© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

No 96

360

R. No
९४०-ई

[illegible]

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

اٰدم بس رمتی

میرسمو ونز دیز رکال بیکہ پاشیان دریخ کرالو ناے سا لدنم اثر

کرالو سونہ ہ پاک ہی

ہمہ فونتہ ہا ر ازی ور [illegible]

امشی سکھ

دیار سی کنی

ساد ن

ترار دیہ پاک سکو مولہ

اہم سکو دعو ر کی

اند جو ہی

والد دیہ پاک

شنیمی سکھ

کک

بیسران

سکو

والد اشنرجو

دسمی

سکھ

ہار

[illegible]

سادن سکو دعو ر کی

والد سکو ن سکی

سادہ سکو

مولسی پاپا

والد سکو ن سکی

جست

سکھ

ثنت علوم

اللہ

کماسوتی

اوزہ وش

ناثی

© Dharmarth Trust. Digitized By eGangotri

Seshanaga, the Serpent King, restores Ar...

MAHABARATA SERIES, No 114 REG...

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible] टीका [illegible]

[illegible] १०३७०॥ [illegible] १०३७०॥

[illegible]

[illegible] १५३०॥ [illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

ॐ श्रीगणेशाय नमः ॐ अस्य श्रीभगव

द्गीतामालामन्त्रस्य श्रीभगवान्वेदव्यास

ऋषिः अनुष्टुप्छन्दः श्रीकृष्णः पर

मात्मा देवता अशोच्यानन्वशोचस्त्वं प्रज्ञा

गी. १ वादांश्च भाषसे इति बीजं सर्वधर्मा

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

गी· १

उज्लवीहं नमः ष्मङ्केयमस्लेय

मल्केमेभृग्वम उिमहूमहं नमः

विंहः मचगाउभुश् गुमलेयंमनाउन ८

हूंभिकहं नमः पक्षुभेपजुपा

मउमेघ भदमूम उिं ॥

© Dharmarth Trust. Digitized By eGangotri

कविमुकुटं नमः नानाविधविधि

ष्टानि नानावर्णकुसुमानि पुष्पकर

उलकारपद्ममुकुटं नमः पुष्पकरं नमः

गन्धधूपदीपं नमः नैवेद्यं क्षिप्तात्रिमसूली

ताम्बूलायनमः नमोनमं नमस्कारं मुपे

© Dharmarth Trust. Digitized By eGangotri

गी॰ ३

ओं अस्य श्रीमद्भगवद्गीतामालामन्त्रस्य

भगवान्वेदव्यास ऋषिः अनु

ष्टुप् छन्दः श्रीकृष्णः परमात्मा देव

ता [illegible] ओं [illegible]

[illegible] श्री

([illegible])

𑆓𑆵𑆠𑆥𑆳𑆜𑆼 𑆮𑆴𑆤𑆴𑆪𑆾𑆓𑆂 𑆃𑆡 𑆣𑇀𑆪𑆳𑆤𑆩𑇀 𑆥𑆳

𑆫𑇀𑆡𑆳𑆪 𑆥𑇀𑆫𑆠𑆴𑆧𑆾𑆣𑆴𑆠𑆳𑆁 𑆨𑆓𑆮𑆠𑆳 𑆤𑆳𑆫𑆳𑆪𑆟𑆼

𑆤 𑆱𑇀𑆮𑆪𑆁 𑆮𑇀𑆪𑆳𑆱𑆼𑆤 𑆓𑇀𑆫𑆡𑆴𑆠𑆳𑆁 𑆥𑆶𑆫𑆳𑆟𑆩𑆶𑆤𑆴

𑆤𑆳 𑆩𑆣𑇀𑆪𑆼 𑆩𑆲𑆳𑆨𑆳𑆫𑆠𑆼 𑆃𑆢𑇀𑆮𑆽𑆠𑆳𑆩𑆸𑆠𑆮𑆫𑇀𑆰𑆴

𑆟𑆵𑆁 𑆨𑆓𑆮𑆠𑆵𑆁 𑆃𑆰𑇀𑆛𑆳𑆢𑆯𑆳𑆣𑇀𑆪𑆳𑆪𑆴𑆤𑆵𑆁 𑆃

© Dharmarth Trust. Digitized By eGangotri

भुवनभास्करमिठगवन्नीडेठव

डेधिल्लीभा ० नभेभुडेह्नभवि

मालवडे डल्लगविन्दयउपड्ने

१ येनद्वयठगउैलपुलः प्लुलि

गी. २ डेल्लुनभयः प्रभीपः १ भुपद्रपाविज्ञ

(ज्यउेस्वैरैकपाल्लये ॥

© Dharmarth Trust. Digitized By eGangotri

[illegible] गोपीजनवल्लभदेवनमः ३

[illegible] गोपालनन्दनः

[illegible] गोपीजनवल्लभ

ॐ [illegible]

[illegible] ४

© Dharmarth Trust. Digitized By eGangotri

ठीभडे॰ञउहम्ञ्यतुबम्ल गान्तु

गनीलेपल मल्तृग् नवडीनपेल्व

ङिनी कल्नवेल्उल ममुक्कभवि

कल्ठ्योरभकर ज़ुदेपनवडुनी भेु

गी॰ डील्गपल्पञुवैःऊजनमीकैवडुकी

५ (केमवे)

© Dharmarth Trust. Digitized By eGangotri

कृष्णः

परमद्वमः भेरेलभुभलं गीउज

गेत्रुक्कं नना्भ्टनककेभंदविक

घ भेम्रेणनवेणिं लेकेभक्लनथ

पमैरङ्गवदः पेथीयभनंभ्रुरु क्रुय

क्रउपक्कणंकलिभल धक्षंभिनःमे

यभे १ भ्रकंकेउिवमलंपक्कुलक्ष्म्यउगिरिभा य

© Dharmarth Trust. Digitized By eGangotri

𑆱𑇀𑆠𑆶𑆪𑆠𑆩𑆶𑆁𑆤𑆮𑆑𑆼 𑆥𑆫𑆩𑆶𑆤𑆑𑇀𑆰𑆩𑆳𑆟𑆮𑆩𑆳 𑇅

𑆪𑆁𑆫𑆑𑇀𑆰𑆮𑆤𑆳 𑆱𑆶𑆤𑆳𑆩𑆤𑆠 𑆱𑆶𑆠𑇀𑆫𑆴𑆱𑇀𑆪𑆽

𑆩𑆶𑆮𑆽 𑆖𑆼𑆱𑆽𑆂𑆱𑆶𑆤𑆥𑆤𑆑𑇀𑆰𑆼𑆩𑆶𑆥𑆴𑆤𑆴𑆯𑆼𑆱𑆼 𑆤𑆳

𑆪𑆠𑇀𑆫𑆴𑆪𑆁𑆩𑆳𑆩𑆓𑆳𑆂 𑆥𑆤𑆶𑆮𑆴𑆩𑆶𑆠𑆱𑇀𑆤𑆼𑆠𑆤𑆩

𑆤𑆩𑆳 𑆥𑆫𑆶𑆠𑇀𑆫𑆴𑆪𑆼𑆪𑆾𑆓𑆴𑆤𑆼 𑆪𑆩𑆶𑆠𑇀𑆫𑆶𑆁𑆤𑆮𑆴𑆢𑇀𑆫𑆂

𑆓𑆵· 𑆩𑆳𑆂 𑆱𑆶𑆤𑆳𑆫𑆱𑆼𑆮𑆪𑆠𑆩𑆼𑆤𑆤𑆩𑆂 𑆥𑆠𑆫𑆱𑆶𑆠𑆂

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

गी ७ [illegible]

© Dharmarth Trust. Digitized By eGangotri

𑆣𑇀𑆫𑆶𑆮𑆑𑆼𑆠𑆶𑆱𑇀𑆤𑆼𑆑𑆴𑆠𑆮𑆂𑆑𑆳𑆩𑆴𑆫𑆱𑆤𑇀𑆤𑆶𑆮𑆵𑆢𑆮𑆤𑆳

𑆣𑆤𑆪𑆾𑆯𑇀𑆖𑆑𑇀𑆰𑆶𑆰𑆂

𑆣𑆤𑆳𑆩𑆴𑆬𑆶𑆠𑇀𑆫𑆴𑆜𑆴𑆬𑆱𑆤𑇀𑆤 𑆩𑆽𑆠𑇀𑆫𑆱𑆶𑆤𑆫𑆣𑆕𑇀𑆓𑆮𑆂 𑇕

𑆱𑆶𑆫𑆂

𑆪𑆟𑆨𑆢𑇀𑆫𑆱𑆶𑆮𑆴𑆑𑇀𑆫𑆳𑆤𑇀𑆠𑆇𑆠𑆨𑆾𑆱𑇀𑆱𑆤𑇀𑆤𑆶𑆮𑆵𑆢𑆮𑆤𑆳

𑆱𑆠𑆴𑆨𑆢𑇀𑆫𑆂 𑆑𑆼𑆥𑆑𑆶𑆁𑆥𑆳𑆤𑆶𑆱𑇀𑆜𑆼𑆪𑆟𑆴𑆯𑇀𑆮𑆴𑆫𑆟𑆶𑆱𑇀𑆡𑆼
𑆱𑇀𑆠𑆂 𑆣𑆸𑆠𑆴𑆮𑆴𑆑𑇀𑆫𑆳𑆤𑇀𑆠𑆪𑆂 𑆥𑆳𑆠𑆶𑇆

𑆨𑆾𑆜𑆑𑆼𑆑𑆼𑆥𑆱𑇀𑆪𑆳𑆤𑇀𑆤 𑆨𑆮𑆳𑆩𑇀𑆧𑆨𑆑𑆫𑆔𑆂 𑇖

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible] १

[illegible]

शी॰ ३ [illegible] ३

© Dharmarth Trust. Digitized By eGangotri

𑆱𑇀𑆠𑆼𑆩𑆮𑆢𑆮𑆂𑆱𑇀𑆠𑆶𑆫 𑆨𑆩𑆱𑆼𑆯𑆤𑆠𑆟𑆵𑆮𑆴𑆘𑇀𑆘𑆂

𑆜𑆓𑆳𑆩𑆇𑆩𑆬𑇀𑆥𑆶𑆣𑆲𑇀𑆱𑇀𑆠𑆪𑆂𑇆

𑆤𑆤𑆳𑆮𑆴𑆟 𑆤𑆴𑆩𑆱𑇀𑆩𑆸𑆠𑆴 𑆨𑆶𑆠𑆳 𑆪𑆴𑆥𑆼𑆱𑇀𑆠𑆶 𑆩𑆟𑆤𑆳𑆤𑆴 𑆝𑆸𑆟𑆼𑆇𑇅 𑆤𑆴𑆥𑆴𑆂

𑆤𑆤 𑆩𑆱𑇀𑆩𑆸𑆣𑆢𑆳𑆂 𑆨𑆮𑆼𑆰𑆶𑆱𑇀𑆠𑆶𑆮𑆴𑆱𑆳𑆣𑆩𑆂 𑇗

𑆱𑆶𑆨𑆩𑆘𑆩𑆳 𑆱𑆶𑆱𑇀𑆥𑆶𑆱𑇀𑆩𑆳𑆤𑆴 𑆮𑆬𑆩𑆳

𑆱𑆶𑆥𑆢𑆥𑆶𑆁𑆝𑆱𑆶𑆱𑇀𑆩𑆑𑆁 𑆮𑆬𑆁𑆜𑆵𑆩𑆳𑆜𑆴𑆮𑆑𑆴𑆁

𑆨𑆩𑆘𑆁 𑆇𑆩𑆨𑆱𑇀𑆩𑆑𑆁𑆮𑆬𑆩𑆳

𑆥𑆢𑆥𑆶𑆁𑆢𑆴𑆱𑇀𑆩𑆼𑆇𑆪𑆁 𑆮𑆬𑆁𑆜𑆵𑆩𑆳𑆜𑆴𑆮𑆑𑆴𑆁 𑇘

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

𑇄 [illegible]

[illegible]

[illegible]

[illegible]

𑇄 [illegible]

𑆬𑆑𑇀𑆰𑇀𑆩𑆵𑆥𑆠𑆴𑆂

[illegible]

© Dharmarth Trust. Digitized By eGangotri

𑆥𑆳𑆚𑇀𑆖𑆘𑆤𑇀𑆪𑆁 𑆲𑆸𑆰𑆵𑆑𑆼𑆯𑆾 𑆢𑆼𑆮𑆢𑆠𑇀𑆠𑆁 𑆣𑆤𑆚𑇀𑆘𑆪𑆂

[illegible] [illegible] [illegible]

𑆥𑆿𑆟𑇀𑆝𑇀𑆫𑆁 𑆢𑆣𑇀𑆩𑆿 𑆩𑆲𑆳𑆯𑆕𑇀𑆒𑆁 𑆨𑆵𑆩𑆑𑆫𑇀𑆩𑆳 𑆮𑆸𑆑𑆾𑆢𑆫𑆂 𑇑𑇕

[illegible]

𑆃𑆤𑆤𑇀𑆠𑆮𑆴𑆘𑆪𑆁 𑆫𑆳𑆘𑆳 𑆑𑆶𑆤𑇀𑆠𑆵𑆥𑆶𑆠𑇀𑆫𑆾 𑆪𑆶𑆣𑆴𑆰𑇀𑆜𑆴𑆫𑆂

𑆓𑆵· 𑇑𑇑 𑆤𑆑𑆶𑆬𑆂 𑆱𑆲𑆢𑆼𑆮𑆯𑇀𑆖 𑆱𑆶𑆔𑆾𑆰𑆩𑆟𑆴𑆥𑆶𑆰𑇀𑆥𑆑𑆿 𑇑𑇖

© Dharmarth Trust. Digitized By eGangotri

कस्त्वं परमेश्वरः शिवः श्रीमद्भगवतः

भगवन्तः गुरोर्गुरुः

परमेश्वरो विगतस्त्वं भवत्किस्त्वं परमितः ०१

देवपतीश्वरः

देवदेवपतेयस्त्वं भगवन् पृथ्वीपते

भैरवस्त्वं भगवन् सर्वज्ञः सर्वशः पञ्चवक्त्र

का ०३

© Dharmarth Trust. Digitized By eGangotri

अथैषे पञ्चामृत[illegible]

[illegible]

[illegible] ०७

[illegible]

[illegible]

सी० [illegible]

००

© Dharmarth Trust. Digitized By eGangotri

𑆲𑆸𑆰𑆵𑆑𑆼𑆯𑆁𑆠𑆢𑆳𑆮𑆳𑆑𑇀𑆪 𑆩𑆴𑆢𑆩𑆳𑆲𑆩𑆲𑆵𑆥𑆠𑆼

𑆃𑆫𑇀𑆘𑆶𑆤𑆇𑆮𑆳𑆖

𑆱𑆼𑆤𑆪𑆾𑆫𑆶𑆨𑆪𑆾𑆫𑇀𑆩𑆣𑇀𑆪𑆼 𑆫𑆡𑆁𑆱𑇀𑆡𑆳𑆥𑆪𑆩𑆼𑆃𑆖𑇀𑆪𑆶𑆠 𑇑𑇐

𑆪𑆳𑆮𑆢𑆼𑆠𑆳𑆤𑇀𑆤𑆴𑆫𑆵𑆑𑇀𑆰𑆼𑆃𑆲𑆁𑆪𑆾𑆢𑇀𑆣𑆶𑆑𑆳𑆩𑆳𑆤𑆮𑆱𑇀𑆡𑆴𑆠

𑆤𑆳 𑆑𑆽𑆫𑇀𑆩𑆪𑆳𑆱𑆲𑆪𑆾𑆢𑇀𑆣𑆮𑇀𑆪𑆩𑆱𑇀𑆩𑆴𑆤𑇀𑆫𑆟𑆱𑆩𑆶𑆢𑇀𑆪𑆩𑆼 𑇑𑇑

© Dharmarth Trust. Digitized By eGangotri

ये त्तु भ न व वे न्नो हं य र क्रे ह भ भ गाऊः

षट्कृ ग व न उ न्न ह्नु द्रू भ न य न म्मे

प त्तु र भ्रू भ्र स व्व क्षे ड त्रु भि य र्मि की ह्ल वः

गुरु कवि.. ज्ञ मुद्रा तहि उगि ॠ ॥ भानुयउवः

स्व भ स्ते ह हृषीके मे ग ङ क्के मे न ठ व उ

श्री. गी. ०७ भे न ये न रु ह्ये ह्न्दे ॠ प यि ह्नु र वे तु भ भी ४२

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible] 𑇑𑇕

[illegible]

[illegible] 𑇑𑇖

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

श्रीमत्त्रिसमगाह्गाङ्गांकपरितुष्टेः
श्रीमत्त्रिविक्रमी सङ्गति
लविठवत्रि॥

कम्पः
देवपूज्यमरीदेभे देवमदपूज्यसत्यते १७

ण्डत्राम
कंपत्रः सुपःपतेः भवतःभवपुते
गाङ्गीवंसभेदमहद्वीवपरिमहते

हंसगस्कुतीव
नमस्कृत्यसर्वमुक्तेहसतीवस्मभिभवः ३॥

© Dharmarth Trust. Digitized By eGangotri

𑆤𑆴𑆩𑆴𑆠𑇀𑆠𑆳𑆤𑆴𑆖𑆥𑆯𑇀𑆪𑆳𑆩𑆴𑆮𑆴𑆥𑆫𑆵𑆠𑆳𑆤𑆴𑆑𑆼𑆯𑆮

[illegible]

𑆤𑆖𑆯𑇀𑆫𑆼𑆪𑆾𑆤𑆶𑆥𑆯𑇀𑆪𑆳𑆩𑆴𑆲𑆠𑇀𑆮𑆳𑆱𑇀𑆮𑆘𑆤𑆩𑆳𑆲𑆼𑆮𑆼 𑇓𑇐

𑆤𑆑𑆳𑆁𑆑𑇀𑆰𑆼𑆮𑆴𑆘𑆪𑆁𑆑𑆸𑆰𑇀𑆟𑆤𑆖𑆫𑆳𑆘𑇀𑆪𑆁𑆱𑆶𑆒𑆳𑆤𑆴𑆖

[illegible]

𑆓𑆵𑇆 𑆑𑆴𑆁𑆤𑆾𑆫𑆳𑆘𑇀𑆪𑆼𑆤𑆓𑆾𑆮𑆴𑆤𑇀𑆢𑆑𑆴𑆁𑆨𑆾𑆓𑆽𑆫𑇀𑆘𑆵𑆮𑆴𑆠𑆼𑆤𑆮𑆳 𑇓𑇑

𑇐𑇒

© Dharmarth Trust. Digitized By eGangotri

𑆪𑆼𑆰𑆨𑆼𑆯𑆑𑆳𑆤𑆼𑆫𑆱𑆶𑆁𑆜𑆼𑆓𑆳𑆂𑆯𑆳𑆥𑆳𑆤𑆴𑆩

𑆥𑆤𑆂𑆱𑆁𑆫𑆑𑇀𑆰

𑆇𑆨𑆼𑆮𑆨𑆴𑆠𑆪𑆢𑆼𑆰𑆁𑆨𑆶𑆑𑇀𑆰𑆥𑆤𑆤𑆴𑆩 𑇓𑇓

𑆱𑆶𑆩𑆳𑆢𑆂𑆥𑆴𑆇𑆂𑆰𑆲𑆨𑆶𑆰𑆼𑆮𑆩𑆥𑆴𑆠𑆨𑆢𑆂

𑆨𑆇𑆬𑆂𑆱𑇀𑆮𑆇𑆫𑆂𑆥𑆼𑆫𑆂𑆨𑆷𑆬𑆨𑇀𑆫𑆧𑇀𑆫𑆠𑇀𑆫𑆴𑆤𑆨

𑆔 𑇓𑆫

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

अस्मात्सुदर्शनं दत्तं गन्तुमभ्युद्यतो ऽभव
येन:
ता
श्रुत्वेति कर्मं दत्त्वाद्यापि नम्रमभाष
वे ३२
लोकेन ज्ञात्वा विवेक:
यत्प्रेरितेन पतितिं लोके पदमसत्तम:
पपमा
जलमयं तं मेघं भित्त्वा देवमय कं ३३

© Dharmarth Trust. Digitized By eGangotri

𑆑𑆡𑆁𑆤𑆘𑇀𑆚𑆼𑆪𑆩𑆱𑇀𑆩𑆳𑆨𑆴𑆂𑆥𑆳𑆥𑆳𑆢𑆱𑇀𑆩𑆳𑆤𑇀𑆤𑆴𑆮
[illegible] \ 𑆫𑇀𑆠𑆴𑆠𑆶𑆩𑇅
[illegible]
𑆑𑆶𑆬𑆑𑇀𑆰𑆪𑆑𑆸𑆠𑆁𑆢𑆾𑆰𑆁𑆥𑇀𑆫𑆥𑆯𑇀𑆪𑆢𑇀𑆨𑆴𑆫𑇀𑆘𑆤𑆳𑆫𑇀𑆢𑆤 𑇓𑇙

[illegible]

𑆑𑆶𑆬𑆑𑇀𑆰𑆪𑆼𑆥𑇀𑆫𑆟𑆯𑇀𑆪𑆤𑇀𑆠𑆴𑆑𑆶𑆬𑆣𑆫𑇀𑆩𑆳𑆂𑆱𑆤𑆳𑆠𑆤𑆳𑆂

[illegible]

𑆓𑆵॰ [illegible]

𑆣𑆫𑇀𑆩𑆼𑆤𑆰𑇀𑆛𑆼𑆑𑆶𑆬𑆁𑆑𑆸𑆠𑇀𑆱𑇀𑆤𑆩𑆣𑆫𑇀𑆩𑆾𑇁𑆨𑆴𑆨𑆮𑆠𑇀𑆪𑆶𑆠 𑇔𑇐

© Dharmarth Trust. Digitized By eGangotri

[illegible]भवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः

स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः १०

सङ्करो नरकायैव कुलघ्नानां कुलस्य च

एषां पितरः लुप्तपिण्ड
मपि नरके पतन्ति॥

पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः १३

© Dharmarth Trust. Digitized By eGangotri

दैवैर्दैः जलप्लावनं वनभङ्गकारकैः

लभ्यते मित्रतुनः

उद्भूतेष्वपि पद्मः जलपद्मसमस्तः २३

नष्टः

उद्भवजलपद्म भवद्य लक्ष्मन

वयमनुसुसूम सुरवरंवरं ह्रभासिहः सूउवतः ध्यासिउ
मुउच्चः पापेषु निरतः भक्तः सपस्नुउपिनः कथ्यन्तिर
यन्ति सतन्त्र निह्नुमि वमनेहः॥

गी. नरके नियतं वा भेदवतीहृतुसमसुम २२
०१

𑆱𑆼𑆢𑆼𑆮𑆠𑆶𑆨𑆓𑆢𑇀𑆝𑆥𑆁 𑆑𑆫𑇀𑆠𑆶𑆁𑆲𑆸𑆮𑆨𑆴𑆠𑆮𑆪𑆨𑆳𑇅
𑆑𑆱𑇀𑆩𑆁

𑆤𑆴𑆱𑇀𑆤𑆪𑆁𑆓𑆠𑆂 𑆱𑆶𑆠𑇀𑆩𑆴𑆱𑆪𑆼𑆤𑆪
𑆮𑆱𑇀𑆠𑆶𑆱𑇀𑆠𑆶𑆁 𑆢𑆮𑆠𑇀𑆠𑆼𑆫𑆠𑆂
𑆪𑆢𑆸𑆗𑇀𑆗𑆳𑆥𑆬𑆼𑆜𑆤𑆢𑆠𑇀𑆠𑆶𑆁𑆱𑇀𑆮𑆩𑆤𑆱𑆸𑆠𑆂 𑇅

𑆥𑆠𑆴𑆪𑆱𑇀𑆤𑆶𑆱𑆶𑆠𑆳𑆮
𑆪𑆱𑇀𑆩𑆴𑆤𑇀𑆨𑆱𑇀𑆥𑆶𑆠𑆵𑆑𑆳𑆫𑆱𑆶𑆩𑆱𑇀𑆠𑆶𑆩𑆱𑆸𑆥𑆳𑆪𑆂

𑆥𑆠𑆶𑆫𑆱𑇀𑆮𑆫𑆼𑆢𑆠𑇀𑆠𑆸𑆱𑆶𑆩𑆼𑆑𑆼𑆱𑆠𑆁𑆜𑆮𑆼𑆢 𑇅
𑆨𑆳𑆫𑆶𑆪𑆠𑆮𑆳𑆱

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible] ॥ २७

इति श्रीभगवद्गीतासूपनिषत्सु ब्रह्मवि-

द्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

गी. ७३ ज्ञानविभागो नाम सप्तमोऽध्यायः ॥ ७ ॥ [illegible]

© Dharmarth Trust. Digitized By eGangotri

𑇄 𑆠𑆪𑆳𑆤𑆥𑆪𑆶𑆮𑆴𑆯𑇀𑆮𑆱𑆶𑆥𑆫𑆬𑆶𑆠𑆬𑆼𑆑𑇀𑆫𑆁

𑆮𑆴𑆰𑆵𑆩𑆠𑇀𑆠𑆨𑆴𑆱𑆶𑆮𑆑𑇀𑆫𑆨𑆶𑆫𑆩𑆨𑆮𑆨𑇀𑆫𑆩𑆤𑆂

𑆯𑇀𑆫𑆵𑆑𑆳𑆮𑆠𑇀𑆮𑆮𑆩

𑆘𑆠𑇀𑆨𑆶𑆑𑆩𑇀𑆩𑆬𑆳𑆨𑆶𑆁𑆮𑆴𑆰𑆨𑆼𑆨𑆶𑆥𑆳𑆨𑆶𑆁𑆠

𑆱𑆤𑆳𑆢𑆛𑇀𑆛𑆯𑇀𑆫𑆶𑆨𑆶𑆯𑇀𑆫𑆶𑆤𑆶𑆨𑆶𑆑𑆵𑆠𑇀𑆫𑆴𑆑𑆳𑆁𑆨𑆶𑆬𑇀𑆬𑆤 𑇑

© Dharmarth Trust. Digitized By eGangotri

𑆃𑆯𑆶𑆑𑆩𑆬𑆩𑆴𑆩𑆶𑆁𑆮𑆴𑆣𑆩𑆼𑆩𑆩𑆶𑆥𑆴𑆩𑆶𑆁

𑆑𑆁𑆠𑆢𑆁 𑆩𑆢𑆮𑆵𑆫 𑆪𑆼𑆠𑆂𑆤𑆠𑆮𑆴𑆠

𑆩𑆤𑆳𑆢𑆢𑆩𑆶𑆩𑆶𑆩𑆶𑆤𑆶𑆩𑆑𑆵𑆠𑆴𑆑𑆫𑆩𑆶𑆬𑆤 𑇅

𑆪𑆢𑆮𑆩𑆢𑆶𑆥𑆴 𑆪𑆼𑆢𑆶𑆩𑆵𑆠𑆴𑆮𑆑𑆶𑆩𑆤
𑆩𑆴𑆠 𑆃𑆢𑆮𑆬𑆾𑆂 𑆑𑆁𑆪𑆼𑆢𑆶𑆩𑆴𑇈

𑆬𑆻𑆢𑆂𑆩𑆩𑆓𑆳𑆩𑆂𑆥𑆓𑆻𑆢𑆶𑆢𑆶𑆥𑆥𑆢𑆼

𑆑𑆠𑆢𑆁 𑆩𑆢𑆶𑆠𑆳𑆥𑆤

𑆓𑆵𑇆 𑆣𑆳𑆁𑆑𑆶𑆪𑆼𑆢𑆬𑆁𑆢𑆑𑆾𑆠𑆴𑆩𑆶𑆥𑆫𑆠𑆥 𑇄

𑇑𑇗 𑆑𑆁𑆢𑆵𑆩𑆁 𑆩𑆁𑆢𑆶𑆩𑆢𑆼 𑆢𑆶𑆩𑆩𑆥𑆩𑆶𑆩𑆤𑇅 𑆩𑆶𑆬𑆤𑆠𑆮𑆩
𑆃𑆴𑆢𑆴𑆢𑆶𑆠𑆴𑆪𑆼𑆢𑆶𑆩𑆴𑆥𑆢𑆢𑆮𑆶𑆩𑆶𑆤 𑇒𑇆

𑇑

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

𑆤𑆩𑆾 𑆓𑆶𑆫𑆶𑆨𑇀𑆪𑆂 𑆑𑆁𑆜𑆫𑆠𑇀𑆤𑆼𑆓𑆟𑆵𑆪𑆼

𑆤𑆩𑆤𑆵𑆪𑆂 𑆑𑆁𑆜𑆱𑇀𑆡𑆼𑆤𑆶 𑆑𑆁𑆜𑆫𑆠𑇀𑆤𑆁 𑆩𑆟𑆴𑆑𑆁𑆜𑆩𑆳 ॥

𑆪𑆢𑇀𑆫𑆱𑇀𑆪𑆼𑆩𑆪𑆳𑆱𑆴𑆮 𑆤𑆼𑆫𑆱𑇀𑆪𑆼𑆮𑆂

𑆫𑆱𑇀𑆪𑆼𑆮𑆶 𑆨𑆑𑇀𑆠 𑆑𑆁𑆜𑆬𑆼𑆂 𑆥𑆫𑆳𑆤 𑆪𑆳𑆤𑇀𑆮𑆼𑆣𑆶𑆫𑆶 𑆪𑆳𑆤𑆼𑆮𑆶𑆠 ॥

𑆪𑆳𑆤𑇀𑆮𑆼𑆮 𑆢𑆑𑇀𑆤𑆳𑆩𑆴𑆬𑆱𑇀𑆤𑆵𑆮𑆴𑆰𑆩

𑆱𑇀𑆤𑆵𑆮𑆴𑆠𑆶𑆩𑆴𑆱𑇀𑆠𑆶𑆩𑆂

𑆩𑆩𑆳𑆥

𑆱𑆼𑆮 𑆩𑆶𑆠𑆂 𑆥𑆩𑆳𑆥𑆥𑆠𑇀𑆫𑆳𑆱𑇀𑆫𑆶𑆂

𑆓𑆵॰ 𑇑॰

© Dharmarth Trust. Digitized By eGangotri

करन्थे मेधे, पदौ भुवः

[illegible]

यस्कुभिन्नं पद्मं भ्रहमेत:

यस्येयः स्र विज्ञिते सु दितमे

सिस्मे स्मापिभं हुं पूपत्रं १

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

गी. १०

[illegible]

© Dharmarth Trust. Digitized By eGangotri

एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप

हृषीकानीन्द्रियाणि तेषां
ईशं नियन्तारम् भगवन्तम् ॥

न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ९

प्रहसन्निव भारत

उवाच हृषीकेशः प्रहसन्निव भारत

सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ॥

(श्रीभगवानुवाच

© Dharmarth Trust. Digitized By eGangotri

सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम

विवेकिनः

देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥ ५२ ॥

नाहं वेदैर्न तपसा न दानेन न चेज्यया ।

गी॰ शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥ ५३ ॥

११

© Dharmarth Trust. Digitized By eGangotri

मदिवैभिन्नरूपमेदेकेभागंयेवनेमग

केभागरूढवस्तुयथा स्थूलभेदनिवर्तनः

सर्वलिङ्गभेद निवर्तनभेदः उपस्थितः॥ पीठः पश्चिद भूरनभूतादि कुर्वकवि भवस्थि नवमाश्च नादिलिपक शुद्धाविन सः॥०३॥

उभयभेदरूपापृथिवीरभूरनभूतादि ०३

उभयाणु विषयैः भद भयुक्तः॥

भारभदमभुकेतेयमीदेशुभाषदः।पमः

उद्धतिविनाम वत्तः॥

उंभितिकास्य भदस्य उत्रिभिउदक्षविध स्थायवमेतरभ्युउभवभूत भूतिभूभवरमी विदृशः ०२॥

भृगाभपृथिवेनिदृशभूंभितिक्रमठगड ०२

© Dharmarth Trust. Digitized By eGangotri

यंदिनहृषयनेुउधनधंधनधद्गठ

श्रुकुपाज ष्ठेउभा।
धनृवय इन्मञ्जः
त्रि॥

भेक्षय

भभरुःापभ्राणंपीशंभेभुउञ्जयकल्पेउ ०४

श्रुभेउनिट्टविनामिनः
मीउेधुरेमृठवःभउ॥

मुञ्जनः

नःभेउविकृउठवेनःठवेविकृउभउः

निलयः

मी· उठयेगुधिम/भुेउभुनयेभुडुमक्षिठिः ०६
९३

६

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

नमयुक्तः

विवेके

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

यस्मन्नवेत्ति न त्वं यस्मैन्न मन्त्रेत मा

सुष्ठुं

उत्तिष्ठेन विस्मृत्य न त्वं यन्न दृष्ट्वा १७

[illegible]

न स्यते श्रियते वाक्यात्रि न त्वं[illegible]

[illegible]

[illegible]

१२

३

© Dharmarth Trust. Digitized By eGangotri

वेद्यविनामिनेनिर्हं यागनभग्नभूयं

स्नाति केद्गउयगीहूनेनभग्नपि निचिकरं
भयेनकत्तुं धमधुंमाकद्दीविहृजेठवति ॥

कथंभधनधः पाजकद्गउयतिनतिकें १०

यथावभूस्तु छिउस्तुबभून मेभभुमिउव भूतुकवा तेनविनस्तु तु सवभस्मि मेनातुकवा ३ः॥

वभांमिरणीलनियथाविदय नवानि

गल्लुतिनेघ्रकालि उथामदीरालिवि

गलीलह्लुतेन वेगत्ताविद्धः॥ ११॥ भूग्रेउ

नयग्णील हृहृनिभंयातिनवानिमेदी ११

© Dharmarth Trust. Digitized By eGangotri

𑆤𑆽𑆤𑆁 𑆗𑆴𑆤𑇀𑆢𑆤𑇀𑆠𑆴 𑆯𑆱𑇀𑆠𑇀𑆫𑆳𑆟𑆴

𑆤𑆽𑆤𑆁 𑆢𑆲𑆠𑆴 𑆥𑆳𑆮𑆑𑆂

𑆤 𑆖𑆽𑆤𑆁 𑆑𑇀𑆬𑆼𑆢𑆪𑆤𑇀𑆠𑇀𑆪𑆳𑆥𑆾

𑆓𑆵. 𑇑𑇕 𑆤 𑆯𑆾𑆰𑆪𑆠𑆴 𑆩𑆳𑆫𑆶𑆠𑆂 𑇒𑇓

𑇑

© Dharmarth Trust. Digitized By eGangotri

मस्कृत्येयमस्कृत्येयमज्ञोऽहमेषु रूपवम

फलिबृध्यमेव यत्नोऽमुना मकरध्वमिद्ध मुधमवेप्रत्यमेनःकस्मृ॥

प्रतिपत्तिम कृत्यस्य कर्म बुद्धिवक्रतिं पमनि निः भवगाउंदः कीर्तिं च गावक अर्द्धस्मृति कृति॥ १३

निः भवगाउः भुम्नमलेयमनउनः १२

मन्दारादृष्टि भयः॥ मनमे दृष्टविषयः दुष्टिस्य ले भस्मेहि कः॥ विवेकिनः

मस्कृत्येयमुमिचैत्येयमुविकल्पेयमस्कृत

उम्म मेदेविविमिद्धेनजमेमित्रमद्भमि १५

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

मध्यगा॒णीवि कुंतवि   संन्यसि

हृदयस्पृनिठाय

भाग्वि

मध्यगनिपनाह्लेव
भवन्तरे सुमज्ञनामप्रपतितः
भनस्त्रुस्मसंगतः नर्तुभोवेस
नर्तुरे कं:म [illegible] क्ष [illegible] सम [illegible] क [illegible]
इक धरिमेवन १५

[illegible] ॥ १३ ॥

© Dharmarth Trust. Digitized By eGangotri

सुसुद्रवद्भूति कस्मिमेन

सा भृ मदेपुमेसुहं पसृत्विम्भयेनपसृति
मृमभ्रु वनः
ठिकुउद्गुग भमुद्रवद्गमति उघैरमत्रुः
मृषव नमे
वकस्मिम्भिड्मृ मचक्रियाठिः मम्रुः १७॥

सुमुद्रवैम्नेनमत्रुः मलेति

विपरीउठवनुठिकुउः

गी. मृद्धेनं वेमनमैवकस्मिउा १७
१७

६

© Dharmarth Trust. Digitized By eGangotri

ऐन्द्री निरुपमां दृष्ट्वा सेवेत भगवत्प्रतिमां ३

स्वनाम्ना सङ्गमं

सन्दर्शनि कृतानन्दं सोऽपि तु सद्गति ३०

सुगमेन सात्त्विकं वेदं सर्वेषु धर्मेषु स्वेनापि विकल्पितुं सद्गति
किम् सुगमं सर्वेषां विकल्पितुं सद्गतीति सम्बन्धः ॥३०॥

सुगमं सर्वेषां विकल्पितुं सद्गति

पश्य सत्
पेशलं॥

पश्येद्य इह सर्वेषु धर्मेषु यः समन्वितः ३०

© Dharmarth Trust. Digitized By eGangotri

यन्मुयमेपपत्रंमुनतुरमपवउमा
मैवेमुय॥ धूर्थ

भठनृः
भापिनःक्षिपयपअलठतेपहुमीस्पमं ३१

ऋः। मषमेषुभिभंपकुं मक्तमंनकािषुभि

गी. ३३ःमुपमंकीडिंम निहुपपमरपुभि ३१
१३

७

© Dharmarth Trust. Digitized By eGangotri

𑆱𑆑𑆵𑆫𑇀𑆠𑆴𑆩𑆶𑆠𑇀𑆥𑆳𑆢𑇀𑆪𑆠𑆳𑆤𑆴𑆑𑆰𑆳𑆪𑆴𑆱𑇀𑆠𑆵𑆫𑇀𑆠𑆴𑆠𑆼𑆁 𑆱𑆁𑆱𑇀𑆠𑆶𑆠𑆵𑆩𑆳

𑆪𑆩𑆾𑆁

𑆮𑆘𑇀𑆚𑆩𑆳
𑆤𑆴𑆠𑇀𑆪𑆩𑆶𑆁 𑆱𑆥𑆴𑆑𑆥𑇀𑆟𑆮𑆠𑆴॥

𑆩𑆩𑇀𑆟𑆮𑆴𑆱𑇀𑆩𑆶𑆠𑆱𑇀𑆑𑆵𑆫𑇀𑆠𑆴𑆩𑆢𑇀𑆮𑆱𑇀𑆠𑆶𑆠𑆴𑆫𑆴𑆠𑆶𑆠𑆼 𑇓𑇒

𑆤𑆴𑆫𑆳𑆠𑆶 𑆩𑆠𑇀𑆠𑆼𑆓𑆤𑆳

𑆟𑆪𑆱𑇀𑆩𑆶𑆢𑇀𑆱𑆶𑆥𑆫𑆠𑆼𑆁𑆩𑆁𑆱𑆶𑆠𑇀𑆠𑆼𑆤𑇀𑆢𑆶𑆁𑆩𑆢𑆫𑆓𑆳𑆂

𑆥𑇀𑆫𑆩𑆶𑆤𑇀𑆩𑆴

𑆪𑆼𑆰𑆁𑆩𑆤𑇀𑆢𑆶𑆮𑆘𑇀𑆚𑆩𑆼𑆠𑆢𑆶𑆤𑇀𑆢𑆪𑆱𑆶𑆩𑆴𑆬𑆳𑆰𑇀𑆪
𑆮𑆩𑆳 𑇓𑇕

© Dharmarth Trust. Digitized By eGangotri

सवसुवनं स्नुवज्ञत्वा सिध्युतिज्वः दिउः

मङ्गवः

निक्षत्तसुववभमहं उउेहृःापउरंत्राकिमा ३०

नमेउश्विस्मुँ कुरुउवमहु॥

पवस्तुथिपिउ वलठापवः उक्षुं॥

नउेवधसृसिभुनंलिङ्वठेमुमेमनी

गी. उस्मनृउिभ्रंकेत्रेययमुद्रुयवनिस्वयः ३१

१७

शापतः पिभभेदद्वलाफलफेरण्यागृ ये

शापत्तिलाधंदत्त्वा भूप
भत्रैवृत्व मत्त्र्हू यंष्टमानः पपंनध्भूमीहृः ॥ ३५ ॥

उेयस्तुयद्वरणस्त्रनैवंपपभरष्टुमि ३३

काष्ठि भष्टृह्ने कर्मयेगे

मषाउेठिदिउभाहृद्वहृदिरोहिंमस्तर्व

ईश्वरे कर्मयेगेन मृदुतःकरणःभना

दृष्टामि

मत्तुयत्तेयययापउकमवत्तुंभदसमि ३४

© Dharmarth Trust. Digitized By eGangotri

वेदृठिकुमनमेमुधष्टवयेनविकृउ

मठिकुमम्‌ धरमठम्‌ ॥ नमेविमुठ रुनरमि ॥ मेनेरविधुवेनुशुरकृरम भठवडा ॥ १० ॥

मुलपमुधमृणमरुरयठेमदउठयजा १०

दृवमयमिकशकुरेकेतउमनकुन

वी० रकमायकृनत्रुमुवशरुयेदृवमयिनं १०

उ०

9

© Dharmarth Trust. Digitized By eGangotri

यस्मिं भाषितं वसं प्रवसन्तु विपाटिताः

[illegible]

वेसवसरः पञ्चकृत्समीप्तिवासिनः ४

[illegible]

कमण्डलुः शृन्तपरल्मकमण्डलुः

[illegible]

क्रियाविशेषवसलं ठेगेसुद्गातिधाति ४

© Dharmarth Trust. Digitized By eGangotri

ओंनमुदम मज्ञानं ध्यपः पहृतमेत्मभा

यथा नमुमेत्मभा

सिद्धकलं ... ॥

ह्रवमयः इष्किकश्च हृदिमम्मम पेनविणीयते २२

इत्याद्येन मकमहेन

विषयवर्त कः खिलवर्तो यन्तु ॥

निष्कमः

इत्यादि विषयवेकृ निमेत्रहेनवज्ञान

ब्रह्मम नमः ॥

नपमितिरहस्य निःशेषद्धि मुक्तो ॥

मधुधुमधु पञ्चयोगः ॥

मधुभतः

गी. ३० निमुद्भिहमवहमु निदेगमेमनुज्ञवचा २४

१

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय

सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ४८

दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय

बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ४९

© Dharmarth Trust. Digitized By eGangotri

बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते

तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलं ॥ ५० ॥

कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः

जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयं ५१

© Dharmarth Trust. Digitized By eGangotri

यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति

कलिलं गहनम्॥

वैराग्यं

तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ॥५२

विक्षेपादिना

श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला

लयादिना

योगफलं तत्त्वज्ञानम्

गी. ३३

समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ॥५

© Dharmarth Trust. Digitized By eGangotri

श्रुतध्रुवस्य कंठथ

किंलक्ष्मभ

भभाणिभ्रुस्त्रकेमव

ह्रक्रिः

श्रुतपीः किंध्रुठथेउ

कथं विषयन्त्युप्रेडि ॥

श्रुतनिस्त्रलःनवज्ञःश्रीउि ध्रुस्तयस्य
म श्रुतध्रुस्त्र स्त्रवभ्रुस्त्रयवान्ना भभाणि
श्रुत्रु ह्रक्रिउमेउस्त्रुउि उमेवमहृरः ध्रुस्त्रः
भभाणिभ्रु श्रुतध्रुस्त्रोणकः ह्रक्रिश्रुत
ध्रुस्त्रोउयः ॥ ५८ ॥

किभःश्रीउग्रलेउकिं ५२ श्रीठगवः

© Dharmarth Trust. Digitized By eGangotri

𑆥𑇀𑆫𑆘𑆲𑆳𑆠𑆴𑆪𑆢𑆳𑆑𑆳𑆩𑆳𑆤𑇀𑆱𑆫𑇀𑆮𑆳𑆤𑇀𑆥𑆳𑆫𑇀𑆡𑆩𑆤𑆾𑆓𑆠𑆳𑆤𑇀

𑆄𑆠𑇀𑆩𑆤𑇀𑆪𑆼𑆮𑆳𑆠𑇀𑆩𑆤𑆳𑆠𑆶𑆰𑇀𑆛𑆂𑆱𑇀𑆡𑆴𑆠𑆥𑇀𑆫𑆘𑇀𑆚𑆱𑇀𑆠𑆢𑆾𑆖𑇀𑆪𑆠𑆼 𑇕𑇕

𑆢𑆶𑆂𑆒𑆼𑆰𑇀𑆮𑆤𑆶𑆢𑇀𑆮𑆴𑆓𑇀𑆤𑆩𑆤𑆳𑆂𑆱𑆶𑆒𑆼𑆰𑆶𑆮𑆴𑆓𑆠𑆱𑇀𑆥𑆸𑆲𑆂

𑆓𑆵 𑇓𑇘 𑆮𑆵𑆠𑆫𑆳𑆓𑆨𑆪𑆑𑇀𑆫𑆾𑆣𑆂𑆱𑇀𑆡𑆴𑆠𑆣𑆵𑆫𑇀𑆩𑆶𑆤𑆴𑆫𑆶𑆖𑇀𑆪𑆠𑆼 𑇕𑇖

© Dharmarth Trust. Digitized By eGangotri

यः भव [illegible]

[illegible]

नमोऽस्तु [illegible]

[illegible] ५७

[illegible]

[illegible] भवन्तः

[illegible]

ॐ ह्रीं [illegible] श्रीं ह्रीं [illegible]

विषयाविनिवर्त्तन्ते निराहारस्य देहिनः

विषयाः तत्त्वेन निवर्त्तन्ते ... इन्द्रियैर्विषयग्रहण... भुजाद्यः

रसो रागोऽपि ... लम्पटत्वम् ... परमात्मानम्

रसवर्जं रसोप्यस्य परं दृष्ट्वा निवर्त्तते ५९

विवेकिनः

यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः

क्षोभकानि ... बलात्

गी. इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ६०

३५

१

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible] [illegible]

[illegible]

[illegible]

[illegible]

[illegible] [illegible]

© Dharmarth Trust. Digitized By eGangotri

सम्मोहः कार्याकार्यविवेकाभावः ॥

क्रोधाद्भवति संमोहः संमोहात्स्मृतिविभ्रमः

[illegible]

स्मृतिभ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ॥ ६३

[illegible]

रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन्

आत्मवश्यैः ॥ विधेयो वशवर्ती [illegible] [illegible]

गी० आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ॥ ६४

३

© Dharmarth Trust. Digitized By eGangotri

धर्मे मे भवतु: यन्नं ... [illegible]

[illegible] ॥

धर्मे मे ... [illegible]

[illegible]

[illegible]

[illegible] ॥

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

यनिमामवकुडनं ड्मूं स्गात्रिमंयमी

उम्मनिम्रु उदत्रुप   पुउिवृमृउे निगलीडेम्रिय:

विषय निम्रुय मो॥

यमूंस्गात्रिकुडनिमानिमापमृडेमुनेः ९७

नानन
मीकि:   मनडिम्नुमदामुमी

मुप्रदम॥ मम्रुलपुडिमुं ममद्रमु

येगीनिम्र ममाइमुप्रेवृनकमाजंवादित्तवडि मपिाद्विम्रिय

विषयः

पःपुविमतियकुरा डकुमयंपुवि

पम्रडयंडविषया मनपुविमते नडाद्मयाने नलीवेगाडंवेमापिमी ९०॥

"सेगकमनमीलं"

मत्रिमवे ममात्रिमःप्रेउिनकमकमी ९०

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

यनिमभवक्रुतनेउभ्रूह्लगाडिंमंयमी

उडिम्रीठगावज्ञीउभ्रयानिषङ्क्रुवक्षवि

ह्रुयंयेगामभ्रेम्रीदष्टुल्लनमंवमे।

भह्नृयेगेनभाक्रिडीयेष्ट्रायः १ मड़

शविक्यारम्भेश्व भकमाउ सुम्नउद्वविषय

नउवम डिह्रुयमीमेङ्कम—भ्रेभउवा

।क्रिस्लनांक्रन॥

तत्किं कर्मणि घोरे मां नियोजयसि केशव ॥१॥

व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे

तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ॥२॥

श्रीभगवानुवाच

लोकेऽस्मिन्द्विविधा निष्ठा पुरा प्रोक्ता मयानघ

गी. ३३ ३ ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनाम् ॥३॥

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन

गी॰ ३ कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ७

© Dharmarth Trust. Digitized By eGangotri

नियंउतनकमअंवकमअइयेहकम॥:

निरकमअहैः फभनाकि॥

मवकमअउतूभृउव मेधुभा मकार७इ्म
मतीगनिवहः कमाउ॥
पिनधाभिक्षु ॥
ओयुंः ॥३॥

मतीरयरुपिमउेनधभिकुमकम॥: ३

विभुतपनाउ

येष्ट्रुदृविकु ५ ७ विन कमलिप्रउे

यमुउकम्‌ इरलेकेयंकमवन:

सीविभुधीरुं

जन

उमुंकमकेउेयभउभक्ः अभाव ७

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

गी.

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

कर्मणैव हि संसिद्धिमास्थिता जनकादयः ।
लोकसंग्रहमेवापि संपश्यन्कर्तुमर्हसि ॥ २० ॥

यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः ।
स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ॥ २१ ॥

© Dharmarth Trust. Digitized By eGangotri

नमोपज्ञ्रभिकण्ठं शिखिलोकेश्वकिञ्चन

मशःनमोवमा स्नु ३ङ्ह्नु नमो ऽति कमकोमेृवृत्तुः॥

मधुधुं।

नःनवधुभवधुं वत्रागवमकम्॥ ११

नःत्रभ्रुयं मनलमःमन।

यस्मिन्कुन्नवतेयं स्फकमस्तुशक्तिः

मत्रवतुरन।

गी. भमवकुमःनवत्तेमत्रशृःपज्ञमवमः १२
२२

३

𑆇𑆑𑇀𑆰𑇀𑆩𑆵𑆱𑇀𑆪𑆓𑇀𑆫𑆴𑆨𑇀𑆫𑆽𑆬𑆼𑆑 𑆤𑆘𑇀𑆚𑆳𑆢𑆁𑆑𑆩𑇀𑆫𑆩𑆼𑆩𑇀𑆫𑆶𑆁

𑆥𑆩𑇀𑆫𑆬𑆼𑆥𑆼𑆤𑆤𑆩𑇀𑆫𑆼𑆪𑆓𑇀𑆫𑆂

𑆨𑆬𑆴𑆤𑆵𑆘𑆢𑆨𑆳

𑆨𑆑𑇀𑆑𑆫𑆩𑆶𑆩𑆑𑆠𑆶𑆩𑆶𑆨𑆶𑆥𑆑𑇀𑆠𑆳𑆨𑆴𑆨𑆂𑆥𑆶𑆫𑆂 𑇑𑇓

𑆩𑆜𑆴𑆤𑆴𑆮

𑆱𑇀𑆛𑆶𑆂 𑆩𑆠𑆶𑆂 𑆨𑆠𑇀𑆮𑆂

𑆩𑆘𑆳𑆂𑆑𑆩𑆢𑆶𑆮𑆴𑆤𑇀𑆢𑆁𑆩𑆼𑆪𑆰𑆘𑆮𑆠𑇀𑆫𑆴𑆜𑆳𑆫𑆶

𑆑𑆠𑆶𑆨𑆴𑆱𑇀𑆑𑆶𑆂

𑆘𑆢𑆳𑆱𑇀𑆛𑆴𑆤𑇀𑆢𑆁𑆩𑆶𑆰𑆂𑆩𑆘𑆳𑆩𑇀𑆤𑆴𑆑𑆵𑆱𑇀𑆮𑆼𑆬𑆑𑆩𑆳𑆱𑇀𑆑𑆁 𑇑𑇔

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा

निष्कामः [illegible]

निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ३०

[illegible]

ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः

[illegible]

श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ३१

गी. [illegible]

© Dharmarth Trust. Digitized By eGangotri

येद्वन्द्वमुद्भयन्ते न त्रिसुत्रि मे मतमा

भवद्रुविभुरङ्कं स्रुत्रिद्विर्न भुन्मे तमः ३३

सन्संगमे सुतरां सुरः सन्तोऽनुन वनापि ३३

सन्ति यत्र कृतानि निगदः किं करिष्ये

ति ३३

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

सूत उवाच ॥ साधकेन प्रयुक्तोऽयं पथं

पठ्यमानि पूजितः

सर्वसिद्धिप्रदः शान्तिसूत्रं धिकमेतस्य

लाभैर्विनियोजितः ॥ ७ ॥ श्रीभगवानुवाच

कमलपत्राक्ष पापघ्न [illegible] अच्युतः

मत्स्यं मत्स्याद्यवतारस्थं विष्णुरूपं देवानां ॥ ७ ॥

© Dharmarth Trust. Digitized By eGangotri

प्रभेनःश्रियजेवकि दषःमन्नेभलेनम

प्रभेनःवजेवकिः भुकदंरून धकमःमिकंकवेहेर॥ भलेनःयजेभुरूज्ञः
धतिविभुयून रुपंभुकदं नकवेति भुक्तुयजेभुयलहृजमव॥

यषेल्वेनःवजेगछ भुषजेनेम भुःवजेभा ३३

गछिस्लेन

भुवंस्तुनभेजन स्तुनिनेनिटवैविग

सघुवे महृरुमति: नमःतुकभः कभन
भुयछगोनमभुति दविषःरभुयडेवकुयर
क॰ छि वच ३३ ति ३७॥

कभजुपे केनेयमसघ्रे नलेनम ३७

गी॰

२३

उक्ष्यिया॰॰ भनेवक्षिुर भ्रुणिक्षुन भ्रुक्षे

स्तै विक्ष्यिग्रस्मि छिमक्रनसिकृधा वक्षिुमुयक्कैविव कक्षुनभ्रुयछ्लेदितं विभेदयाभे

स्तैविभेदयछेक्षुक्षुनभ्रुयछ्सेदिनमा १९

विभेदरु चभरु॥

ज्मग्रभ्रुक्ष्यियछ्रुस्सेनियभ्रुठरउक्ष्वठ

पाजय कंभं सुनम भुयि॥ विक्षुनभ्रुठव भुयेजमकमा॥

पाफ्नंधश्लदिहेनंक्षुन विक्षुननकमनं २०

© Dharmarth Trust. Digitized By eGangotri

इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः

महत्वाभिः श्लोकद्वयेन यत इन्द्रियाणि विषयासक्तानि [illegible] मनसस्तु [illegible] बुद्धेः [illegible] [illegible] अतः [illegible] इन्द्रियेभ्यः [illegible] कथं मनसो बुद्धेः [illegible] इति परतस्तु [illegible] ॥ ४२ ॥

प्रथम इन्द्रियाणि विषयेभ्यः सूक्ष्मत्वात् [illegible] इन्द्रियेभ्यः सूक्ष्मं मनः [illegible] मनसो बुद्धिः सूक्ष्मा [illegible]

[illegible]

गी. मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ४२

४७

३

उपसंहरति सप्तमिः

सर्वत्रेद्धः पर्वत्रत्तु मे भुहृत्स्म नभःस्मा

भवतः मृगःपेनः भमनीयं

विविक्त…

त्वहिमङ्क्षेभकवकेकभक्तुपंक्तिकभमः २३

उत्थिश्रीठाकवक्ष्मीडभ्रपनिभक्षुवक्षवि

हृष्टंधेगामभ्रेश्रीनभक्षुक्तनभंवमे

कम्भयेगेनभङ्घ्रीधेमापः ३ श्रीठाक.

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

वङ्गनिमेवृडीङनिरन्कनिठवमङ्लन

मलधुविहुमक्तिहुग । मविस्मुमड्ड गो॥

ङत्रुंवेसमवा। नहुंवङुपरुप ४

मनसुरम्र च्वेपि॥ क्रुनभीमुः कद्मपयकुदी प्रयिमना

मलेपिमवहुयङ्मकुङनभीमुगेपिम ना

धुलङिंमुमङ्गीयं परंमुठव मङ्मिर उम्नमभुमुङपव १॥ मुम्रुयुवञ मे॥ मुमुङमुमङ्गा॥

गी॰ धुलङिंमुमङिमुयमम्ठवमुङ्मभायय १

१०

२

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

𑆪𑆼𑆪𑆡𑆳𑆩𑆳𑆁𑆥𑇀𑆫𑆥𑆢𑇀𑆪𑆤𑇀𑆠𑆼𑆠𑆳𑆁𑆱𑇀𑆠𑆡𑆽𑆮𑆨𑆘𑆳𑆩𑇀𑆪𑆲𑆁

[illegible]

𑆩𑆩𑆮𑆫𑇀𑆠𑇀𑆩𑆳𑆤𑆶𑆮𑆫𑇀𑆠𑆤𑇀𑆠𑆼𑆩𑆤𑆶𑆰𑇀𑆪𑆳𑆂𑆥𑆳𑆫𑇀𑆡𑆱𑆫𑇀𑆮𑆯𑆂 𑇑𑇑

[illegible]

𑆑𑆳𑆕𑇀𑆑𑇀𑆰𑆤𑇀𑆠𑆂𑆑𑆫𑇀𑆩𑆟𑆳𑆁𑆱𑆴𑆢𑇀𑆣𑆴𑆁𑆪𑆘𑆤𑇀𑆠𑆇𑆲𑆢𑆼𑆮𑆠𑆳𑆂

[illegible]

𑆑𑇀𑆰𑆴𑆥𑇀𑆫𑆁𑆲𑆴𑆩𑆳𑆤𑆶𑆰𑆼𑆬𑆾𑆑𑆼𑆱𑆴𑆢𑇀𑆣𑆴𑆫𑇀𑆨𑆮𑆠𑆴𑆑𑆫𑇀𑆩𑆘𑆳 𑇑𑇒

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

यश्रुभवेभभाऽरम्भः कभमङ्कलवालि
\कमसि छलं ३३\ ङः

स्तुनाऽत्रिन मयूरुकम कंनीऽनिकम स्यघमं॥ ३भी भल्गुयमस्मीलि यभिङ्ङ३भ्रु ३नहृ३ङ स्तुरुं॥०७॥

स्तुनाऽत्रिमयूरुकमऽंऽ३भाऽस्रुः यभिङ३वण: ०७

कमसिछले: कऽभङ्गकमाऽस्तुऽत्रिम कं कनाऽछिलयं मरुङ्कु॥ निहृनविऽ: नङ्घेनङ्घृ: निऽसूयःयेगम्रे भाऽऽभाऽसूयली यवादिऽः॥७०॥

स्तुनाकमछलाऽभङ्गं निरुङ्घेनिऽसूयः

३भ्रुकमाऽकम ३भाऽयम्हेङ स्तुरुं॥

गी॰ कमर्ङऽछियुवांङ्घिनेऽवकिम्निकोऽभः ७॰
५५

© Dharmarth Trust. Digitized By eGangotri

निरस्तीदम्भिमुक्तकृतज्ञभवपरिग्रहः निश्रमः
निष्कृमनः मनीगः
पापमां
मार्गं केवलं कर्म जायते प्रेतकिल्बि
मधुजिदुपास्ति
लठेनमत्वम्भः॥ सुमनः निर्वेदः षमा १०
यस्मिन्कुले तमस्त्वेवं तज्जगीते विभज्यः
नष्ट
विधि
सर्वदि
तः॥ यस्मिन्कुल
तम्भः पि॥ विधिर्देव
तविकेवक
मनत्वपि॥
भवभिन्नवृत्तिभिन्नेमनस्त्वः पिननिवृत्ते ११

© Dharmarth Trust. Digitized By eGangotri

𑆓𑆠𑆱𑆕𑇀𑆓𑆱𑇀𑆪 𑆩𑆶𑆑𑇀𑆠𑆱𑇀𑆪 𑆘𑇀𑆚𑆳𑆤𑆳𑆮𑆱𑇀𑆡𑆴𑆠𑆖𑆼𑆠𑆱𑆂

[illegible]

𑆪𑆘𑇀𑆚𑆳𑆪𑆳𑆖𑆫𑆠𑆂 𑆑𑆫𑇀𑆩 𑆱𑆩𑆓𑇀𑆫𑆁 𑆥𑇀𑆫𑆮𑆴𑆬𑆵𑆪𑆠𑆼 𑇒𑇓

[illegible]

𑆧𑇀𑆫𑆲𑇀𑆩𑆳𑆫𑇀𑆥𑆟𑆁 𑆧𑇀𑆫𑆲𑇀𑆩 𑆲𑆮𑆴𑆫𑇀𑆧𑇀𑆫𑆲𑇀𑆩𑆳𑆓𑇀𑆤𑆿 𑆧𑇀𑆫𑆲𑇀𑆩𑆟𑆳 𑆲𑆶𑆠𑆁

[illegible] 𑇒𑇔

𑆧𑇀𑆫𑆲𑇀𑆩𑆽𑆮 𑆠𑆼𑆤 𑆓𑆤𑇀𑆠𑆮𑇀𑆪𑆁 𑆧𑇀𑆫𑆲𑇀𑆩𑆑𑆫𑇀𑆩𑆱𑆩𑆳𑆣𑆴𑆤𑆳 𑇒𑇔

© Dharmarth Trust. Digitized By eGangotri

𑇑 𑆢𑆽𑆮𑆩𑆼𑆮𑆳𑆥𑆫𑆼 𑆪𑆚𑇀𑆘𑆁 𑆪𑆾𑆓𑆴𑆤𑆂 𑆥𑆫𑇀𑆪𑆶𑆥𑆳𑆱𑆠𑆼

𑇒 𑆧𑇀𑆫𑆲𑇀𑆩𑆳𑆓𑇀𑆤𑆳𑆮𑆥𑆫𑆼 𑆪𑆚𑇀𑆘𑆁 𑆪𑆚𑇀𑆘𑆼𑆤𑆽𑆮𑆾𑆥𑆘𑆶𑆲𑇀𑆮𑆠𑆴 𑇒𑇕

𑇓 𑆯𑇀𑆫𑆾𑆠𑇀𑆫𑆳𑆢𑆵𑆤𑆵𑆤𑇀𑆢𑇀𑆫𑆴𑆪𑆳𑆟𑇀𑆪𑆤𑇀𑆪𑆼 𑆱𑆁𑆪𑆩𑆳𑆓𑇀𑆤𑆴𑆰𑆶 𑆘𑆶𑆲𑇀𑆮𑆠𑆴

𑇔 𑆯𑆧𑇀𑆢𑆳𑆢𑆵𑆤𑇀𑆮𑆴𑆰𑆪𑆳𑆤𑆤𑇀𑆪 𑆅𑆤𑇀𑆢𑇀𑆫𑆴𑆪𑆳𑆓𑇀𑆤𑆴𑆰𑆶 𑆘𑆶𑆲𑇀𑆮𑆠𑆴 𑇒𑇖

© Dharmarth Trust. Digitized By eGangotri

भव॰ श्रीद्वियकस्य

स्व॰ मजनस्मीनिवमनेफैमनस्मीनिम॥

वक्तिनभन, यनस्मी नि॥ फलपवा उपनि॥ पूंयसमगुहस्यसिम्न: मंयग्रहनिभव कस्य उपर मयत्तीहः कः ९१॥

फु॰ कस्य ॰ मं, पथे

पूंनिनिभ्रुः॥

सुस्म मंयभयेगाःग्रे

गी॰ ५१

मु॰ क्रडि स्तुनस्मीपिठे ९१

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible] ॥ ११ ॥

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible] ॥ ३० ॥

[illegible] ३०

[illegible]

[illegible] ३१

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

यस्तुत्तनयस्नेह मेवंपरमिपरत्तव

वत्तुवप्ःसि निभितुभा। सर्वे मनत्तभाःत्नंभ यिपरभाःत्नि मत्रेन स्वत्ताभि ॥ ३५॥

येनकुत्तत्तमेषेः स्वत्ताम्तमत्वेभयि ३५

मत्तिमयेनपापकरी

मांहिपार्थव्यपाश्रित्य येऽपिस्युःपापयोनयः ॥

भः

पांपमभृ

मवंस्त्तनश्चवेत्नेव पश्चिन्नंभत्तविमुक्तिभि ३६

॥

यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन ।

[illegible]

ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ॥ ३७

[illegible]

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ।

[illegible]

गी. तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ॥ ३८

𑆱𑆲𑆱𑇀𑆫𑆁 𑆧𑇀𑆫𑆲𑇀𑆩𑆟𑆾𑆃𑆱𑇀𑆠𑆶𑆤𑆼 𑆃𑆢𑇀𑆨𑆶𑆠𑆂 𑆨𑆁𑆪𑆠𑆾𑆃𑆢𑇀𑆨𑆴𑆪𑆂

𑆇𑆩𑆼𑆑𑆶𑆤𑆴𑆩𑇀𑆤𑆂

𑆱𑇀𑆠𑆶𑆤𑆁 𑆬𑆑𑇀𑆰𑇀𑆩𑆥𑆁 𑆩𑆠𑇀𑆫𑆴𑆨𑆶𑆩𑆴𑆫𑆼 𑆠𑆶 𑆥𑆴𑆓𑆳𑆱𑆶𑆠𑆴 𑇓𑇗

𑆱𑆲𑇀𑆫𑆾𑆱𑇀𑆩𑆂 𑆱𑆩𑇀𑆩𑆥 𑆤𑆩𑇀𑆮𑆁 𑆨𑆁𑆩𑆪𑆠𑇀𑆫𑆩𑇀 𑆮𑆴𑆤𑆱𑆶𑆠𑆴

𑆥𑆱𑆴𑆢𑇀𑆢𑆶𑆥𑆴𑆨𑆁𑆩𑆪𑆠𑇀𑆫𑆩𑇀 𑆨𑆮𑆰𑆤𑆱𑆶𑆠𑆴 𑆪𑆠𑆨𑆶𑆱𑇀𑆠𑆂 𑆪𑆁 𑆬𑆾𑆑𑆼𑆤 𑆨𑆴
𑆥𑆤𑆂 𑆬𑆤𑆮𑆴𑆮 𑆢𑆱𑇀𑆠𑆶 𑆨𑆴𑆢𑇀𑆢𑆶𑆂 𑆤𑆩𑆥𑆫𑆬𑆾𑆑𑆂 𑆥𑆩𑆱𑇀𑆠𑆂 𑆤𑆴𑆰𑆼𑆠𑆂
𑆤𑆩𑆨𑇀𑆫𑆳𑆥𑆁 𑆨𑆁𑆩𑆪𑆼 𑆢𑇀𑆢𑆽𑆮 𑆜𑆟𑆨𑆱𑇀𑆠𑆂 𑆥𑆱𑇀𑆠𑆮𑆠 𑇆𑇑𑇐𑇆

𑆤𑆂 𑆪𑆁 𑆬𑆾𑆑𑆼 𑆨𑆶𑆤 𑆥𑆼𑆤 𑆤𑆨𑇀𑆫𑆳𑆥𑆁 𑆨𑆁𑆩𑆪𑆠𑇀𑆫𑆳𑆂 𑇑𑇐

© Dharmarth Trust. Digitized By eGangotri

येगाभत्रभुकम्म ॥ ज्ञनभंस्तुवभंमयं

धवभुम्रुवःदणनेनउभिन्नभ्रुभःप्रितानि कम्म ॥ येनउं॥

ज्ञ नेनःज्ञवेपेनभंकिवः भंमये मेदज्ञिभं नेयेनउभ। ११

मुज्ञवनंनकम्म ॥ निवश्रत्रिपनाज्ञय १०

ज्ञानयग

उज्ञनःज्ञ

वज्ञनभा॥

उभ्रमज्ञनभंकुउ ज्ञज्ञज्ञनःभिनःज्ञनः

कम्मयेगाभःमृय ३३म पूवभं

धम्रुउयपज्ञयेउभ्रु॥ ११॥

गी॰ स्तुवैज्ञनंभंमययेगाभःउभ्रुउभुवउ ११

१०

© Dharmarth Trust. Digitized By eGangotri

ॐ श्रीठगावज्ञीउन्प्रपनि· वृक्षविह्

यंग्येगमाभ्रे श्रीनभुल्लनभंवमेक

भमंत्रभयेगेनभमउजेषृयः १ म

यभुःभजिरभुपिद्रु दिनाझुनिनः
कभंत्रभंकखयभि झुनःभिन
भंमय [illegible] येग [illegible] कवयुधि॥ || ल्लनउवम

ठिभत्रभंकभ [illegible] नमुपनेगामनेनाति

यस्त्रुयपउयेरेकं उन्मेत्रुदिभविम्निउभा ०

|| श्रीठगलत्नवम ||

© Dharmarth Trust. Digitized By eGangotri

मनसाभः कर्मयोगमसक्तः स विशिष्यते

निःसृयभकरवेऽ ... मेंके ... योगि ॥

... कर्मयोगमसक्तः स विशिष्यते ७

... मनि ... भ ... यनकर्म ...

रागद्वेष ...

... ॥

गी॰ ... भ ... प्रसिद्ध्येदकर्मणः ८

७१

५

© Dharmarth Trust. Digitized By eGangotri

भङ्क्येगोपक्षघ्नालः ध्रुवमत्तिनपाङ्गुः

भत्तृभ कृमये ठित्रे भ्रान्वः

गो॥

त्रम्रिङः॥ भत्टूग्रि कृत्र्वाति॥ सः॥ कैवल्यभा

एकमभूर्णमिङः भमूत्ठयेविक्षेठलं २

लठे

यङ्गाङ्कैः प प्रेमुनंङ्कैगेग्रपिगभूङ सपाथे

भाग्वमभृक्रातृडि॥

एकंभागंमयेगंमयः पमुङिमथमृङि ४

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

नैराकित्निक्कोभीतियुक्तोभवेद्व्वविदा

कर्मयोगे नयज्ञः॥ इभल्लद्दविक्कृव

मन्त्रसाम्भित्तिरु नैम्रियैः॥

पमहं यक्तु भुल्लेन

यत्सुर्व्वद्ध्यालिप्य नग्नजत्कब्धयत्र

भत ३

वत्म पद्मप्रभृहं दुलहं॥ इमहाहभुल्लेन॥

ध्रलयविभन्नजदुत्तुम्भिधविभिधव पि

मन्त्रहीन भिम्भियं यभिश्रुविधयेषु पूजाविधिमम क्रियायुं नहुत्रं नेनपरमुलं पंः॥७॥

यक्तु निम्भित्तत

उम्भियशीम्भियुरोधवन्त्तडिणयय ना ७

© Dharmarth Trust. Digitized By eGangotri

ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः

लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ॥

कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि

कर्मयोगिनः

गी. योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ॥

७४

५

© Dharmarth Trust. Digitized By eGangotri

𑆤𑆑𑆫𑇀𑆠𑆸𑆠𑇀𑆮𑆁𑆤𑆑𑆫𑇀𑆩𑆳𑆟𑆴 𑆬𑆾𑆑𑆱𑇀𑆪𑆱𑆸𑆘𑆠𑆴𑆥𑇀𑆫𑆨𑆶𑆂

[illegible]

𑆤𑆑𑆫𑇀𑆩𑆦𑆬𑆱𑆁𑆪𑆾𑆓𑆁 𑆱𑇀𑆮𑆨𑆳𑆮𑆱𑇀𑆠𑆶𑆥𑇀𑆫𑆮𑆫𑇀𑆠𑆠𑆼 𑇑𑇔

[illegible]

𑆤𑆳𑆢𑆠𑇀𑆠𑆼𑆑𑆱𑇀𑆪𑆖𑆴𑆠𑇀𑆥𑆳𑆥𑆁 𑆤𑆖𑆽𑆮𑆱𑆶𑆑𑆸𑆠𑆁𑆮𑆴𑆨𑆶𑆂

[illegible] 𑇑𑇕

𑆓𑆵. 𑆃𑆘𑇀𑆚𑆳𑆤𑆼𑆤𑆳𑆮𑆸𑆠𑆁𑆘𑇀𑆚𑆳𑆤𑆁 𑆠𑆼𑆤𑆩𑆶𑆲𑇀𑆪𑆤𑇀𑆠𑆴𑆘𑆤𑇀𑆠𑆮𑆂 𑇑𑇕

© Dharmarth Trust. Digitized By eGangotri

𑆘𑇀𑆚𑆳𑆤𑆼𑆤 𑆠𑆶 𑆠𑆢𑆘𑇀𑆚𑆳𑆤𑆁 𑆪𑆼𑆰𑆳𑆁 𑆤𑆳𑆯𑆴𑆠𑆩𑆳𑆠𑇀𑆩𑆤𑆂

𑆪𑆡𑆳 𑆃𑆢𑆴𑆠𑇀𑆪𑆂 ... 𑆮𑆱𑇀𑆠𑆶𑆘𑆳𑆠𑆁 𑆥𑇀𑆫𑆑𑆳𑆯𑆪𑆠𑆴 ॥

𑆠𑆼𑆰𑆳𑆩𑆳𑆢𑆴𑆠𑇀𑆪𑆮𑆓𑇀𑆘𑇀𑆚𑆳𑆤𑆁 𑆥𑇀𑆫𑆑𑆳𑆯𑆪𑆠𑆴 𑆠𑆠𑇀𑆥𑆫𑆩𑇀 ॥ 𑇑𑇖

𑆩𑆤𑆂 𑆠𑆢𑆳𑆠𑇀𑆩𑆳 𑆠𑆠𑇀𑆥𑆫𑆂

𑆠𑆢𑇀𑆧𑆶𑆢𑇀𑆣𑆪𑆱𑇀𑆠𑆢𑆳𑆠𑇀𑆩𑆳𑆤𑆱𑇀𑆠𑆤𑇀𑆤𑆴𑆰𑇀𑆜𑆳𑆱𑇀𑆠𑆠𑇀𑆥𑆫𑆳𑆪𑆟𑆳𑆂

𑆩𑆶𑆑𑇀𑆠𑆴𑆁 𑆘𑇀𑆚𑆳𑆤𑆼𑆤 𑆤𑆴𑆫𑆱𑇀𑆠𑆁 𑆑𑆊𑇀𑆩𑆰𑆁 𑆪𑆼𑆰𑆳𑆁

𑆓𑆖𑇀𑆗𑆤𑇀𑆠𑇀𑆪𑆥𑆶𑆤𑆫𑆳𑆮𑆸𑆠𑇀𑆠𑆴𑆁 𑆘𑇀𑆚𑆳𑆤𑆤𑆴𑆫𑇀𑆣𑆷𑆠𑆑𑆊𑇀𑆩𑆰𑆳𑆂 𑇑𑇗

© Dharmarth Trust. Digitized By eGangotri

विक्रू विनयमभ्रते सूक्ष्मेगाविदमिनि

विक्रू नकुपभ्रुभ्रुनं विनयः॥ सूक्ष्मेम गाविमंक्षु
चेतुंम माढि गधीनयंरा
के॥ लभु॥

मंशूभयं उघ दभिनि सुनिशु
पकेमः इतुरभमे मवःपमेधि॥ पभिदुश भुमंपसूत्रेर नउ
ममंसूवद... ॥

सुनिमेवसुपकेम पभिदुः मभमाभ्नः ०३

सूनीवस्थिरेर मंमाः

उदेवतेलिङः मजे येषं मभ्रेभिङंमनः

विमि धंवं सकरन घरगाङ्घ घरकवम सवमल॥ रेमभमाभ्निः ०३

मी॰ निम्रधंदिममंवक्ष उम्मसूक्ष्मिरेभिङः ०३

© Dharmarth Trust. Digitized By eGangotri

नंधरुहश्रेद्विंयंभप्रनेद्विस्लेदृप्रमाध्रुयं

निम्न्लभाउः॥ निवउभेदः॥ नविधीमउ नंधरुहश्रेमिट्मिना भृठवाण्वः३मिउः नथन वेधृप्रवेविवणः १०

भ्रुवशद्विरभम्रुठेवफ्रविदुफ्रांभ्रु ३ः १०

भुक्रान्तः काले यकुप्तमभठुकं भाद्विकंभ्राप ३द्विक्षउलंठवे ऊरुकंठगउ यम्रकभम्रापलेके यम्रामिटंभदऊ्रापभा उधं मयभापभेउ नाऽदऊः घेरमीकलाभउ॥

वर्टे विधयेधु॥ मिउः

वरुभ्पमेश्रभउऊम्रविंक्रटऊ्रम्नियऊ्राप

भेमेभृमभभापलब्रु वृफ्रांपेगेन भभाणिन घ्रउभभे ठं भ्रभत्रुद्भयश्टभः॥ मकयमाप भम्रुउ ॥१०॥

भयभ्रयेगाघ्रउऊम्रभापभम्रयभम्रुउ १०

© Dharmarth Trust. Digitized By eGangotri

योऽसिसंसद्ग्रस्थेना स्तुःपयेनय स्वते
कथना
संसद्ग्रस्थेया विशयेष्टे स्तुतनिभ्राफनि ॥

वनुभानुकलेऽपि सदवस्थया मिथ्र्वमुद्दस्तुःपमैवका स्तुतः
धप्रैश्वर्येगोष विप्रेगान्यप्रेधप्रेषधजनाकस्तुःपमुस्य
॥ठिसारस्थेगा स्तुःपमेवस्वनयति ११ ॥ विवेकी

मुहूर्त्तवत्तःकौन्तेय नेषुरसते वपः ११

स्तुतपातपदत्तमा ॥

सक्रेडीहैवयःसेकं धज्ञागीगविसेकत्वा

कसवेगेम तृणवेगेगारधकस्तुधप्रैस्तम
नेनेस्क्रेठःभिः क्रम्प्रेभुधचनेस्तुपभिः ११ ॥
॥ममभाद्रितः ॥
गी॰
१७ कम दूपेरुववेगं भयत्तः समुआपीनवः ११

© Dharmarth Trust. Digitized By eGangotri

येत्रः भुपित्तरा रभ भुषा त्रुल्लेगिरेवयः

मुरभुमुः त्रेवःस्नेरवरहु॥ नेपाक्लिभापं उैरह्नम रभडे॥

ग्रमाभुःमुःकामःहवनेडभ्रम्हव भिवउत्तंम रग्नुउंवविमोमवम भडिगिउि १२॥

भयगीभ्रक्रनिव॑भ्रक्रुउडुणिगमुडि ३२

भ्रक्रान्लयभा

मभूवम्लिनः॥

लठनेभ्रक्रनिव॑भधयःमी॑कल्मषः

क्विन्नभंमयः

यडभिउः

नपलवः

भ्रिन्नसैणयडुस्नःमवक्रुउल्किडेरडः १४

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

ॐ इति श्रीभगवद्गीतासु. ब्र. वि. योगशास्त्रे

श्रीकृष्णार्जुनसंवादे भक्तियोगो नाम

द्वादशोऽध्यायः १२ श्रीभगवानुवाच इदम्

[illegible]

[illegible] कमलं [illegible]

[illegible]

[illegible] ० ॥

© Dharmarth Trust. Digitized By eGangotri

𑆪𑆁 𑆩𑆠𑇀𑆫𑆳𑆩𑆴𑆠𑆴𑆩𑆸𑆓 𑆢𑆼𑆮𑆳𑆁𑆠𑆮𑆴𑆢𑇀𑆫𑆴𑆥𑆕𑇀𑆫𑆮

𑆩𑆼𑆱𑇀𑆩𑆼𑆤𑆓𑆂

𑆤𑆲𑆩𑆠𑇀𑆫𑆸𑆠𑆟𑆑𑆬𑇀𑆥𑆼 𑆪𑆼𑆤𑆳𑆝𑆮𑆠𑆴𑆑𑆱𑇀𑆩𑆤 𑇑

𑆩𑆠𑆶𑆩𑆴𑆱𑇀𑆠𑆶𑆂

𑆩𑆥𑆑𑆁

𑆓𑆤𑇀𑆩𑆾𑆩𑆤𑆼𑆢𑆁 𑆑𑆩𑆑𑆳𑆫𑆟𑆩𑆶𑆖𑇀𑆪𑆠𑆼

𑆥𑆮𑆁𑆑𑆩𑆴 𑆟𑆂 𑆩𑆠𑆂𑇆 𑆱𑆩𑆩𑆼𑆮𑆶𑆢𑆪 𑆟𑆢𑆵𑆠𑆶 𑇆

𑆪𑆼𑆤𑆳𑆠𑇀𑆩𑆥𑇀𑆫𑆠𑆩𑆼𑆠𑇀𑆫 𑆱𑆩𑆂 𑆑𑆳𑆫𑆟𑆩𑆶𑆖𑇀𑆪𑆠𑆼

𑆱𑆩𑆂

© Dharmarth Trust. Digitized By eGangotri

यस्मा दिनेमृय ऽभ्र नकमस्तु ऽखस्तु ते

विषयेषु   विषयाज्ञानादिषु ॥

योगं प्राप्य मुक्तः पुरुषः ॥

भवभक्त्यन्तरात्मा योगारूढ ऽमुमूते २

विवेकयुक्तेन ॥   मदीयेन

उद्धरेदात्मनात्मानं नात्मानमवसादयेत्

मद्भक्तपाठ मनः

वस्तुरूपकारकः ॥

विपर्ययकारकः ॥

आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ५

अविवेक

विवेकयुक्तेन

गी.

१०

[illegible]

[illegible]

[illegible] केवलं [illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

सुख विसृन दुख सुख ज्ञान विविध ब्रह्मियः

[illegible]

यज्ञं स्मृत्येयेगी भमलेशु स्मकान्न: ३

[illegible]

भहस्मिह दुस भीन भप्रभुवेप्रपनुप ४

[illegible]

गी. १० भववृधिमपपेभ भभद्विविमिभुरे ७

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

निस्मूलं भवे

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

𑆪𑆱𑇀𑆩𑆴𑆤𑇀 𑆮𑆴𑆤𑆴𑆪𑆠𑆼 𑆩𑆴𑆠𑇀𑆫𑆨𑇀𑆫𑆳𑆤𑇀𑆠𑆼𑆫𑇀𑆮𑆳𑆮𑆠𑆴𑆰𑇀𑆜𑆠𑆼

𑆱𑆁𑆪𑆠𑆁 𑆩𑆴𑆠𑇀𑆫𑆪𑆳
𑆤𑆴𑆫𑇀𑆩𑆷𑆬𑆁 𑆪𑆡𑆳 𑆩𑆸𑆠𑇀𑆪𑆶𑆪𑆾𑆒𑆂𑇅

𑆤𑆴𑆫𑇀𑆩𑆷𑆬𑆂 𑆱𑆫𑇀𑆮𑆑𑆫𑇀𑆩𑆼𑆨𑇀𑆪𑆾 𑆪𑆘𑇀𑆚𑆼𑆠𑆷𑆱𑇀𑆩𑆸𑆠𑆾𑆱𑇀𑆪 [illegible]

𑆱𑆫𑇀𑆮𑆠𑆂

𑆪𑆠𑇀𑆫𑆱𑇀𑆡𑆵𑆪𑆼 𑆤𑆴𑆮𑆫𑇀𑆠𑆤𑇀𑆠𑆼 𑆩𑆼𑆥𑆩𑆳𑆩𑆳𑆠

𑆱𑆫𑇀𑆮𑆠𑆂

𑆪𑆼𑆒𑆴𑆤𑆴𑆪𑆠𑆩𑆴𑆠𑇀𑆫𑆱𑇀𑆪 𑆥𑆳𑆥𑆼𑆨𑇀𑆪𑆾 𑆨𑆑𑇀𑆠𑆂 [illegible]

© Dharmarth Trust. Digitized By eGangotri

𑆪𑆠𑇀𑆫𑆾𑆥𑆫𑆩𑆠𑆼 𑆖𑆴𑆠𑇀𑆠𑆁 𑆤𑆴𑆫𑆶𑆢𑇀𑆣𑆁 𑆪𑆾𑆓𑆱𑆼𑆮𑆪𑆳

[illegible]

𑆪𑆠𑇀𑆫 𑆖𑆽𑆮𑆳𑆠𑇀𑆩𑆤𑆳𑆠𑇀𑆩𑆳𑆤𑆁 𑆥𑆯𑇀𑆪𑆤𑇀𑆤𑆳𑆠𑇀𑆩𑆤𑆴 𑆠𑆶𑆰𑇀𑆪𑆠𑆴 𑇒𑇐

[illegible]

𑆱𑆶𑆒𑆩𑆳𑆠𑇀𑆪𑆤𑇀𑆠𑆴𑆑𑆁 𑆪𑆠𑇀𑆠𑆢𑇀𑆧𑆶𑆢𑇀𑆣𑆴𑆓𑇀𑆫𑆳𑆲𑇀𑆪𑆩𑆠𑆵𑆤𑇀𑆢𑇀𑆫𑆴𑆪𑆩𑇀

[illegible]

𑆓𑆵 𑇗𑇒 𑆮𑆼𑆠𑇀𑆠𑆴 𑆪𑆠𑇀𑆫 𑆤 𑆖𑆽𑆮𑆳𑆪𑆁 𑆱𑇀𑆡𑆴𑆠𑆯𑇀𑆖𑆬𑆠𑆴 𑆠𑆠𑇀𑆠𑇀𑆮𑆠𑆂 𑇒𑇐

© Dharmarth Trust. Digitized By eGangotri

𑆪𑆁 𑆬𑆧𑇀𑆣𑇀𑆮𑆳 𑆖𑆳𑆥𑆫𑆁 𑆬𑆳𑆨𑆁 𑆩𑆤𑇀𑆪𑆠𑆼 𑆤𑆳𑆣𑆴𑆑𑆁 𑆠𑆠𑆂

𑆪𑆩𑆳𑆠𑇀𑆩𑆬𑆳𑆨𑆩𑆳𑆥𑇀𑆪 𑆖𑆳𑆥𑆫𑆁 𑆬𑆳𑆨𑆁 𑆬𑆧𑇀𑆣𑇀𑆮𑆳 𑆠𑆠𑆾𑆃𑆣𑆴𑆑𑆩𑆥𑆫𑆁 [illegible]
𑆬𑆳𑆨𑆁 𑆤 𑆩𑆤𑇀𑆪𑆠𑆼 𑆠𑆠𑇀𑆫𑆽𑆮 𑆤𑆴𑆮𑆸𑆠𑇀𑆠𑆴𑆩𑆪𑆩𑆳𑆠𑇀𑆩𑆥𑆢𑆁 𑇒𑇒

[illegible]

𑆪𑆱𑇀𑆩𑆴𑆤𑇀𑆱𑇀𑆡𑆴𑆠𑆾 𑆤 𑆢𑆶𑆂𑆒𑆼𑆤 𑆓𑆶𑆫𑆶𑆟𑆳𑆥𑆴 𑆮𑆴𑆖𑆳𑆬𑇀𑆪𑆠𑆼 𑇒𑇒

[illegible] 𑇆𑇒𑇓𑇆

𑆠𑆁 𑆮𑆴𑆢𑇀𑆪𑆳𑆢𑇀𑆢𑆶𑆂𑆒𑆱𑆁𑆪𑆾𑆓𑆮𑆴𑆪𑆾𑆓𑆁 𑆪𑆾𑆓𑆱𑆁𑆘𑇀𑆚𑆴𑆠𑆩𑇀

[illegible] 𑇆𑇒𑇓𑇆

𑆱 𑆤𑆴𑆯𑇀𑆖𑆪𑆼𑆤 𑆪𑆾𑆑𑇀𑆠𑆮𑇀𑆪𑆾 𑆪𑆾𑆓𑆾𑆃𑆤𑆴𑆫𑇀𑆮𑆴𑆟𑇀𑆟𑆖𑆼𑆠𑆱𑆳 𑇒𑇓

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

𑆪𑆠𑆾 𑆪𑆠𑆾 𑆤𑆴𑆯𑇀𑆖𑆫𑆠𑆴 𑆩𑆤𑆯𑇀𑆖𑆚𑇀𑆖𑆬𑆩𑆱𑇀𑆡𑆴𑆫𑆩𑇀

𑆪𑆁 𑆪𑆁 𑆮𑆴𑆰𑆪𑆁 𑆥𑇀𑆫𑆠𑆴

𑆠𑆠𑆱𑇀𑆠𑆠𑆾 𑆤𑆴𑆪𑆩𑇀𑆪𑆽𑆠𑆢𑆳𑆠𑇀𑆩𑆤𑇀𑆪𑆼𑆮 𑆮𑆯𑆁 𑆤𑆪𑆼𑆠𑇀 𑇒𑇖

𑆥𑇀𑆫𑆯𑆳𑆤𑇀𑆠𑆩𑆤𑆱𑆁 𑆲𑇀𑆪𑆼𑆤𑆁 𑆪𑆾𑆓𑆴𑆤𑆁 𑆱𑆶𑆒𑆩𑆶𑆠𑇀𑆠𑆩𑆩𑇀

𑆈𑆥𑆽𑆠𑆴 𑆯𑆳𑆤𑇀𑆠𑆫𑆘𑆱𑆁 𑆧𑇀𑆫𑆲𑇀𑆩𑆨𑆷𑆠𑆩𑆑𑆬𑇀𑆩𑆰𑆩𑇀 𑇒𑇗

© Dharmarth Trust. Digitized By eGangotri

𑆪𑆶𑆚𑇀𑆘𑆤𑇀𑆤𑆼𑆮𑆁 𑆱𑆢𑆳𑆠𑇀𑆩𑆳𑆤𑆁 𑆪𑆾𑆓𑆵𑆮𑆴𑆓𑆠𑆑𑆬𑇀𑆩𑆰𑆂

𑆱𑆶𑆒𑆼𑆤 𑆧𑇀𑆫𑆲𑇀𑆩𑆱𑆁𑆱𑇀𑆥𑆫𑇀𑆯𑆩𑆠𑇀𑆪𑆤𑇀𑆠𑆁 𑆱𑆶𑆒𑆩𑆯𑇀𑆤𑆶𑆠𑆼 𑇢𑇨

𑆱𑆫𑇀𑆮𑆨𑆷𑆠𑆱𑇀𑆡𑆩𑆳𑆠𑇀𑆩𑆳𑆤𑆁 𑆱𑆫𑇀𑆮𑆨𑆷𑆠𑆳𑆤𑆴 𑆖𑆳𑆠𑇀𑆩𑆤𑆴

𑆓𑆵𑇅 𑆇𑆑𑇀𑆰𑆠𑆼 𑆪𑆾𑆓𑆪𑆶𑆑𑇀𑆠𑆳𑆠𑇀𑆩𑆳 𑆱𑆫𑇀𑆮𑆠𑇀𑆫 𑆱𑆩𑆢𑆫𑇀𑆯𑆤𑆂 𑇢𑇩

𑇧𑇢

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible] ॥ ३३ ॥

[illegible] ३३

[illegible]

[illegible] ॥ ३३ ॥

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

𑆖𑆚𑇀𑆖𑆬𑆁𑆲𑆴𑆩𑆤𑆂𑆑𑆸𑆰𑇀𑆟 𑆥𑇀𑆫𑆩𑆳𑆡𑆴𑆧𑆬𑆮𑆢𑇀𑆢𑆸𑆞𑆩𑇀

𑆠𑆱𑇀𑆪𑆳𑆲𑆁𑆤𑆴𑆓𑇀𑆫𑆲𑆁𑆩𑆤𑇀𑆪𑆼𑆮𑆳𑆪𑆾𑆫𑆴𑆮𑆱𑆶𑆢𑆶𑆰𑇀𑆑𑆫𑆩𑇀 𑇓𑇔

𑆯𑇀𑆫𑆵𑆨𑆓𑆮𑆳𑆤𑆶𑆮𑆳𑆖 𑇆

𑆃𑆱𑆁𑆯𑆪𑆁𑆩𑆲𑆳𑆧𑆳𑆲𑆾𑆩𑆤𑆾𑆢𑆶𑆫𑇀𑆤𑆴𑆓𑇀𑆫𑆲𑆁𑆖𑆬𑆩𑇀

𑆃𑆨𑇀𑆪𑆳𑆱𑆼𑆤𑆠𑆶𑆑𑆿𑆤𑇀𑆠𑆼𑆪 𑆮𑆽𑆫𑆳𑆓𑇀𑆪𑆼𑆟𑆖𑆓𑆸𑆲𑇀𑆪𑆠𑆼 𑇓𑇕

© Dharmarth Trust. Digitized By eGangotri

𑆃𑆱𑆁𑆪𑆠𑆳𑆠𑇀𑆩𑆤𑆳 𑆪𑆺𑆓𑆺 𑆢𑆶𑆰𑇀𑆥𑇀𑆫𑆳𑆥 𑆅𑆠𑆴 𑆩𑆼 𑆩𑆠𑆴𑆂

𑆮𑆯𑇀𑆪𑆳𑆠𑇀𑆩𑆤𑆳 𑆠𑆶 𑆪𑆠𑆠𑆳 𑆯𑆑𑇀𑆪𑆺𑆮𑆳𑆥𑇀𑆠𑆶𑆩𑆶𑆥𑆳𑆪𑆠𑆂 𑇓𑇖

𑆃𑆪𑆠𑆴𑆂 𑆯𑇀𑆫𑆢𑇀𑆣𑆪𑆺𑆥𑆼𑆠𑆺 𑆪𑆺𑆓𑆳𑆖𑇀𑆖𑆬𑆴𑆠𑆩𑆳𑆤𑆱𑆂

𑆃𑆥𑇀𑆫𑆳𑆥𑇀𑆪 𑆪𑆺𑆓𑆱𑆁𑆱𑆴𑆢𑇀𑆣𑆴𑆁 𑆑𑆳𑆁 𑆓𑆠𑆴𑆁 𑆑𑆸𑆰𑇀𑆤 𑆓𑆖𑇀𑆗𑆠𑆴 𑇓𑇗

𑆓𑆵 𑇑𑇑

𑆓𑆵 𑇑𑇓

© Dharmarth Trust. Digitized By eGangotri

कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति

भक्तः

[illegible] श्रीपरमेश्वरे [illegible] नश्यति । योगान्निवृत्तो [illegible] नश्यति [illegible] विलीयते

अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ३८

निराश्रयः [illegible]मार्गे

एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः

निवर्तकः येन न भवति ॥

त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ३९

श्रीभगवानुवाच ॥

© Dharmarth Trust. Digitized By eGangotri

पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते । न

हि कल्याणकृत्कश्चिद्दुर्गतिं तात गच्छति ॥ ४० ॥

प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः ।

शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ॥ ४१ ॥

गी. ७७

© Dharmarth Trust. Digitized By eGangotri

मुषवयेगिनभेरुजलेठवडिपीभंडभ।

ठेगावभनविरकृत येगनिभ्रुनंमागिकु

मुक्षतंपीभंड वुक्षविकुवंजलेगोदे

मुकमिवकुठवडि॥

मउझिजलठंलेकेमयमीसुमं २७

झिधूके धतल्कनि वुक्षविध यय वकु मंये गभा॥

उउझंवझिमंयेगं लठउपेवमेदिकभा

पउउमउउकुयःमंभिकुजगनकुन २७

© Dharmarth Trust. Digitized By eGangotri

पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः

जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ४४

प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः

अनेकजन्मसंसिद्धस्ततो याति परां गतिं ४५

गी. ३.

𑆇𑆥𑆱𑇀𑆡𑆴𑆠𑆼𑆥𑆴 𑆑𑆼𑆪𑆾𑆓𑆵 𑆤𑆴𑆫𑆶𑆢𑇀𑆪𑆼𑆥𑆴 𑆱𑆼𑆠𑆼𑆥𑆴 𑆑𑆂

𑆠𑆱𑇀𑆩𑆴𑆤𑇀 𑆱𑆶𑆥𑇀𑆠𑆼 𑆇𑆥𑆼 𑆤𑆴𑆫𑆶𑆢𑇀𑆣𑆼𑆂 ॥ 𑆑𑆼𑆮𑆬𑆩𑆳𑆠𑇀𑆩𑆠𑆤𑇀𑆩𑆪𑆂

𑆇𑆥𑆱𑇀𑆡𑆠𑆼𑆥𑆴 𑆑𑆴𑆩𑇀 𑆲𑆶𑆂 ॥

𑆑𑆱𑇀𑆩𑆴𑆤𑇀 𑆱𑆶𑆥𑇀𑆠𑆼𑆥𑆴 𑆑𑆼𑆪𑆾𑆓𑆵 𑆇𑆩𑆤𑇀𑆩𑆼𑆓𑆵𑆟𑆮𑆂 𑆲𑆶 𑆤𑆼 𑆲𑆶

𑆩𑆼𑆲 𑆩𑆤𑆱𑆳 𑆱𑆠𑆂 𑆑𑆳𑆬𑆩𑆢𑆴𑆠𑆂 ॥

𑆪𑆾𑆓𑆴𑆤𑆩𑆥𑆴 𑆱𑆼𑆮𑆼𑆣𑆀 𑆱𑆤𑇀𑆤𑆼𑆤𑆳𑆠𑆫

𑆱𑆵𑆥𑆫𑆱𑆼𑆠 𑆪𑆱𑆶𑆠𑆥𑆱𑆳 𑆱𑆥𑆶𑆠𑇀𑆠𑆼𑆱𑆼𑆣 𑆤𑆥𑆶𑆤𑇀𑆣 𑆱𑆶𑆥𑇀𑆠 𑆱𑆱𑆱𑆠𑆂 𑆱𑆠𑆱𑆑𑆾 𑆑𑆾𑆟𑆮𑆠𑆟𑆮𑆂 ॥𑆑𑆴॥

𑆱𑆶𑆮 𑆑𑆬𑆼𑆠𑆼𑆪𑆼𑆱𑆀 𑆱𑆱𑆼𑆣𑆶𑆠𑆠𑆱𑆼𑆱𑆠𑆂 𑇒𑇑

© Dharmarth Trust. Digitized By eGangotri

ऽ इति श्रीभगवद्गीतासूपनिषत्सु ब्रह्मविद्

यं येगासमे श्रीदक्षुल्लनभंवमेमुह्मं

त्रिविद्धय भाःसुत्रभुह्नं भंयेगं भभूली विउभो

हल्लीयभुवेमल्ली मैस्सुत्रंकृप

श्रीदूके ॥१०॥ यभयेगेनभ धमुष्टयः १ श्रीभगवानुवाच

सृतिनिविष्वभनः

सुहूभन सुनहूसग

ःभना

त्रिभक्षुभत्रभनःपञ्चयेगंयालुभमस्तुयः

सुविडले वसुद

सिमोदि ॥

गी० सुभंसयंभभगंभंयघसूतभिउत्र १ ०

३०

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

[illegible]

प्रभूतिः

विकटं

भक्तैः

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

गी. ३

१०

© Dharmarth Trust. Digitized By eGangotri

भयमृत्युयुद्धमृत्युरणभीरवे [illegible]

[illegible] कवचं [illegible] ॥

लब्ध्वा [illegible]

॥ ११

विनश्वरम्।

[illegible] सम्भवम्

[illegible] ॥ १२॥

[illegible] ॥ १३

© Dharmarth Trust. Digitized By eGangotri

𑆱𑆫𑇀𑆮𑆠𑇀𑆫𑆁 𑆲𑆫𑆴𑆁 𑆨𑆳𑆮𑆪𑆤𑇀𑆠𑆁 𑆱𑆫𑇀𑆮𑆼𑆰𑆶 𑆨𑆓𑆮𑆢𑇀𑆫𑆷𑆥𑆂

𑆱𑆫𑇀𑆮𑆠𑇀𑆫 𑆥𑇀𑆫𑆥𑆚𑇀𑆖𑆼 𑆲𑆫𑆴𑆁 𑆨𑆓𑆮𑆤𑇀𑆠𑆁 𑆱𑇀𑆩𑆫𑆤𑇀 𑆱𑆫𑇀𑆮𑆼𑆰𑆶 𑆨𑆓𑆮𑆢𑇀𑆫𑆷𑆥𑆂
𑆢𑆸𑆱𑇀𑆛𑇀𑆮𑆳 𑇆 𑆤𑆮𑆩𑆳𑆪𑆤𑇀𑆠𑆁 𑆥𑆶𑆫𑆶𑆰𑆩𑇀 𑇆 𑇑𑇔 𑇆

𑆱𑆫𑇀𑆮𑆱𑆩𑆁 𑆥𑆯𑇀𑆪𑆤𑇀 𑇆 𑆤𑆴𑆫𑆤𑇀𑆠𑆫𑆩𑇀 𑆱𑆫𑇀𑆮𑆠𑇀𑆫 𑆱𑆩𑆩𑇀
𑆥𑆯𑇀𑆪𑆤𑇀 𑆱𑆫𑇀𑆮𑆠𑇀𑆫 𑆱𑆩𑆁 𑆲𑆸𑆢𑆪𑆼 𑆨𑆓𑆮𑆤𑇀𑆠𑆁 𑆱𑆩𑆩𑇀 𑇅 𑇑𑇔

𑆤𑆳𑆲𑆁 𑆢𑆼𑆲𑆂 𑆑𑆱𑇀𑆪 𑆱𑆂 𑆱𑆫𑇀𑆮𑆁 𑆨𑆷𑆠𑆼𑆤 𑆩𑆳𑆪𑆪𑆳 𑆩𑆩𑆳𑆑𑆸𑆠𑆂

𑆱𑆫𑇀𑆮𑆱𑇀𑆪 𑆤𑆳𑆯𑆑 𑆱𑆂 𑆱𑆫𑇀𑆮𑆩𑇀 𑆱𑆫𑇀𑆮𑆁 𑆱𑆫𑇀𑆮𑆼𑆤 𑆱𑆫𑇀𑆮𑆩𑆴 𑆑𑆴
𑆠𑆶 𑆱𑆩𑇀𑆮𑆤𑆼 𑆱𑆫𑇀𑆮𑆁 𑆮𑆴𑆲𑆁 𑆱𑆤𑇀𑆠𑆁 𑆥𑆩𑆳𑆪 𑆠𑆴
𑆱𑆮𑆴𑆲𑆁 𑆱𑆩𑆁 𑆑𑆴𑆚𑇀𑆖𑆴𑆢𑇀 𑆤𑆳𑆱𑇀𑆠𑆴 𑆬𑆾𑆑𑆼 𑆑𑆴𑆁 𑆩𑆳𑆪𑆳
𑆩𑆳𑆪𑆳 𑆥𑆶𑆫𑆶𑆰𑆩𑇀 𑆱𑆾𑆲𑆁 𑇑𑇕 𑇆

𑆓𑆵𑇈 𑆱𑆾𑆲𑆁 𑆤𑆳𑆱𑇀𑆠𑆴 𑆬𑆾𑆑𑆼 𑆱𑆩𑆱𑇀𑆪 𑆱𑆫𑇀𑆮𑆱𑆩𑆁 𑆲𑆸𑆢𑆪𑆩𑇀 𑇅 𑇑𑇕
𑇓𑇗

© Dharmarth Trust. Digitized By eGangotri

वेदः दंभभङ्गी३निवत्तुभनविसङ्कन
रुनभि

सेहाःम्भ
क्र्भ्भां

ठविष्टः॥भक्त३निभं३वेसनकस्नन ११

उक्तड्रेषभभङ्गेनह्क्रुभेदेनठ२३

भंजेभुलसंदेड्रड्रे भहं उरुनङ्गालेउक्तष्टड्र उङ्गालेम ड्रेषभाष्टं
भभङ्ग३यः सी३ड्रुःरि निभित्तिभेदः विवेकं३मभुजन भवङ्ग३नि
भंभे भभृःभेः वभाणी भःणी गङ्गा भ्भः निर्विभ भुवति भरेभन रुनति ११॥
भवङ्ग३निभभेदंभंजेयात्तिपर३य ११

© Dharmarth Trust. Digitized By eGangotri

येषं त्रुतनउपपं सन्नानं पृष्टकमः

भवधतिवत्रुकं पृष्टसवल्लमीलानं

उत्त्रुभेदनिम्रुजाठसन्तेभंमरूवउः ३३

सन्नाभाल्लभेकायभभाःसुहयउत्रिये

उत्त्वुंक्रुउस्त्रिदःनक्रुभपृष्टंकमभसःपिलं ३७

बी० ३३

भ्रातृभिः पितृभिः पुत्रैः पौत्रैः प्रियैर्मयैर्विसृः
श्रीकृष्णाः स्त्रियैश्च भगवन्तेऽर्जुनः ॥

ध्रुवं कल्लोलितं भुविस्तृतमेऽर्जुन ॥ ३० ॥

इति श्रीभगवद्गीतासूपनिषत्सु ब्रह्मवि

द्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

र्जुनविषादयोगो नाम प्रथमोऽध्यायः १

मङ्गलं ददातु

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible] ॥ १ ॥

[illegible] ०

केनधकेन ॥

[illegible]

केनेप्रयेन नियतस्मितुः

गी. [illegible] ३

३७

श्रीभगवानुवाच

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible] 1

[illegible]

[illegible] 1

[illegible]

[illegible]

[illegible]

[illegible] 3

© Dharmarth Trust. Digitized By eGangotri

कविंधरा॥ भद्रमाभिरा भलिरलीयं

भचलं स्वनःशिभिर्दु नियत्रां भक्ताभ्रृंशिप्र ऌभा॥

पेथकं

भभद्रभ्भरेहः भचभृपञरभामिनृह्

स्पपविभि उभधिमऌ॥ भूयुक्त सऌकभो॥

५ भःभिरबलं उभभःधुरभुडा ७

कलेभनभामलेन स्त्रीयुक्ते

भूय॥ कालेभनभामलेन

भभःकि बलेनस्य घञः॥ स्तुऌभरे

योगबलेनमेव श्रवभशेषु॥ भावस्य

भभ कातंपरंधनयभःपेडिस्विभा ॥

गी.
७०

© Dharmarth Trust. Digitized By eGangotri

यमक्ष्मांवेक्षविमेवमत्ति विमत्रिय

भूयश्चवत्तुः॥ वेरूत्तकूः॥ तु गुरुजले

ऋज्येवीऽरगाः यस्मिन्तेवक्रमदं

मवत्ति उऽपमं भन्दे धूवन्ते ॥०॥

भनेहमिनिकश बहुमार भजेचना॥

भवक्ष्रगा मंयमभूभनेहमिनिकृस

ऋभये सर्स्पृः॥ मुक्ष विभयमभा पिवृधभा

भवृणयक्ष्मः धू भः मिुउयेगपाव ।भा ०१

ॐमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन्

यः प्रयाति त्यजन्देहं स याति परमां गतिं १३

अनन्यचेताः सततं यो मां स्मरति नित्यशः

गी.
तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः १४

७३

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

𑆃𑆮𑇀𑆪𑆑𑇀𑆠𑆾𑇁𑆑𑇀𑆰𑆫𑆅𑆠𑇀𑆪𑆶𑆑𑇀𑆠𑆱𑇀 𑆠𑆩𑆳𑆲𑆶𑆂𑆥𑆫𑆩𑆳𑆁𑆓𑆠𑆴𑆁

𑆃𑆠𑆵𑆤𑇀𑆢𑇀𑆫𑆴𑆪𑆂 𑆥𑇀𑆫𑆬𑆪𑆼𑆤𑆳𑆤𑆯𑇀𑆮𑆫𑆂𑇅 𑆠𑆢𑆼𑆮𑆥𑆫𑆳𑆓𑆠𑆴𑆮𑆴𑆢𑆶𑆫𑇀𑆧𑆶𑆣𑆳𑆂𑇆

𑆠𑆢𑇀𑆧𑇀𑆫𑆲𑇀𑆩 𑆱𑆼𑆮 𑆣𑆳𑆩 𑆱𑇀𑆮𑆫𑆷𑆥𑆁𑇆

𑆪𑆁𑆥𑇀𑆫𑆳𑆥𑇀𑆪𑆤𑆤𑆴𑆮𑆫𑇀𑆠𑆤𑇀𑆠𑆼 𑆠𑆢𑇀𑆣𑆳𑆩𑆥𑆫𑆩𑆁𑆩𑆩 𑇑𑇐

𑆤𑆴𑆰𑇀𑆑𑆩𑆪𑆂𑇆

𑆥𑆶𑆫𑆶𑆰𑆂𑆱𑆥𑆫𑆂𑆥𑆳𑆫𑇀𑆡 𑆨𑆑𑇀𑆠𑇀𑆪𑆳𑆬𑆨𑇀𑆪𑆱𑇀𑆠𑇀𑆮𑆤𑆤𑇀𑆪𑆪𑆳

𑆱𑆫𑇀𑆮𑆼𑆨𑆷𑆠𑆳𑆤𑆴

𑆮𑇀𑆪𑆳𑆥𑇀𑆠𑆩𑇅

𑆓𑆵· 𑆪𑆱𑇀𑆪𑆳𑆤𑇀𑆠𑆂𑆱𑇀𑆡𑆳𑆤𑆴𑆨𑆷𑆠𑆳𑆤𑆴𑆪𑆼𑆤𑆱𑆫𑇀𑆮𑆩𑆴𑆢𑆁𑆠𑆠𑆁 𑇑𑇑
𑇗𑇘

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

ब्रमेरदिभुवनस्थ: ॥

[illegible]

यमेजसमस्ति...यवनमा

[illegible] ॥

उरमाम्भमंस्रोति दे

[illegible] ॥

गी. १५ गीभुयु निवद्धे १५ ॥

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

ॐ इति श्रीभगवद्गीतासूपनिषत्सु ब्रह्मवि-

द्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुरुषो-

त्तमयोगो नाम पञ्चदशोऽध्यायः १५ श्रीभगवान्

अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः

दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम्

रमणविहूरमण्त्रहूंपाविशभिरुभुत्रभं

विहूभूगोघ्रुम्रमरुउमेमुष्टं॥ मरत्रुपवनेयषलेलः

मध्रुठलमा पम्रमनपुं पर्युमवषम ठलवुग॥ ममयष्ठ लहुठ ३ ७ रुवमु म॥

धूटमारुवगाभंणम्रुभुभुाापकत्रुभहूयं

भूमकंभापेनक उुमटाभा ७॥

ममूम्रुणनःधूनखणम्रमुमृपरत्रुप

उपयरत्रुेभमधृ भुयेलरुधूयत्रु मपि भमधृष॥ भालम्रनेवह्यम्नि धूनःधूनरुपउत्रि ॥३॥

गी. मधूधूभं निवत्रुेमरुमंभारुवह्यम्नि ३

९७

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

यथाङ्कमभ्रितेनिर्हंवयः भचरगेभदना

उथा भवाभ्यिक्कुतानिभक्ष्मनीरूपणय १

भवक्कुतानिकेनेयर्धश्चडियातिभभिकं

कल्पमजयेधनभुनिकल्पनेविभज्जभुं

मी ७१

© Dharmarth Trust. Digitized By eGangotri

𑆃𑆡 𑆥𑆸𑆶𑆜𑆼 𑆥𑆷𑆘𑆪𑆼𑆠𑇀 𑆃𑆩𑆫𑆳𑆩𑆫𑆳

𑆢𑆼𑆮𑆠𑆳𑆤𑆼𑆤 𑆑𑆼𑆤𑆪 𑆱𑆁𑆓𑆳𑆢𑆶 𑆥𑆫𑆶𑆮𑆸𑆠𑆼 𑇅𑇅

𑆱𑆮𑆱𑇀𑆤𑆠𑆶𑆩𑆁 𑆥𑆫𑆱𑆳 𑆩𑆳𑆤𑆼 𑆢𑆵𑆤 𑆩𑆳𑆱𑆶𑆠𑆁

𑆥𑆁𑆖𑆮 𑆩𑆶𑆱𑇀𑆤𑆠𑆼 𑆩𑆩𑆑𑆶𑆠 𑆩𑆢𑆼𑆮𑆫𑆩𑆳 𑇅𑇅

𑆓𑆵°
𑇑𑇑

© Dharmarth Trust. Digitized By eGangotri

मेध्यन्मभेध्यकम्म ॥ मेध्यस्तुनं विमेउभः

उधभः कुङ्कमस्तुनंनिश्चुलभरम्नुविधयहुग॥ यिक्षिधुमेउभः॥

मंभुस्तुन॥

मुभंगीकभमध॥ मि वकलंगमलंमी गकुंमीदिंसमः मि पुमुंगभंमीम पुलतिंमिङ॥ भमवुस्न दुगुउभुविं ॥ वुयः॥०१॥

गक्ष्मीभः भंगीमैवधलुउिंभेफनंीमिङः ०१

भक्तम्न सुभंपजमैंवीधलुउिभःमिङः

कभस्तुत्रुठिस्तुउः भाङ्किकीभा

मलगाङ्क ः नितिंम मस्तु॥

ठलत्तुनुङभननभेस्तुद्रकुङः मिभहुयभा ०३

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

गमृतेत्ड्रिः पेष नियत्त मंठसुतये गमकः दिउकत्त
ठल॥ कत्त॥ मृष्ठु॥

गठित्त्पत्रअंसीनिवभःमरःभृष्ठा

भष्ठु अंदत्त मृणरः। लयभुनं। ४

धूठवः धूलयभुनं निणनेचीस्प्लभदूयं ०३

४ मविनासिक
यः नउत्रीहृक्षि
वीरुवत्रस्रभा॥ गीक्षमभये॥ करुसित्र धृष्ठुभमये॥

उपभुदमदंवधंनिगलुमृक्षुस्प्लभिम

स्लीवनं भम्भुलंमद्वं
भमभ्रुमुभमु
मृभा॥

गी॰ मभंउसेवभङ्स्र भमृभस्रदभज्ञन ०७
०॰०

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

मंदादिभवयस्तुनं ठेक्तामधक्तुरेवम

।भुभीठलमाङः॥

सर्वेकं अंऽ ऽस्युनयपवने, ठिपनाति

ॐ ३३ मेतऽपुत्रमेंधनवःयतुते

नऽभभुठिस्नत्रिऽस्वेनऽस्तुवत्रिते १२

मृवनभेवः मेवधनि

नयत्रीति॥ यभवतुः

यत्रिमेवस्तुऽमेवान्धिस्तृत्रिपस्तृवऽः॥

क्तेधप्रल

येधं ऽक्रुते,

स्नुः॥

मस्थितेन मस्नुस्नक्तः भमेरुः कयंयभःवस भक्तुंयय त्रि १४॥

क्तुऽनियत्रिक्रुऽस्नुयत्रिमस्तुमिनेपि

।भभौ १५

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri.

[illegible]

[illegible]

[illegible]

[illegible]

गी.
०.२

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

साधिभूताधिदैवं मां साधियज्ञं च ये विदुः

[illegible]

प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ३०

[illegible] युक्तचेतसः मताः ॥

ॐ इति श्रीभगवद्गीतासूपनिषत्सु ब्रह्मविद्या

यां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञान

गी. १०.५ विज्ञानयोगो नाम सप्तमोऽध्यायः ७

श्रीभगवानुवाच ॥

© Dharmarth Trust. Digitized By eGangotri

धिक्रुयज्ञवमदवदेमञ्जभेपवमंवसः

यजुंरंधीयम ॐ यवक्राभिद्विकमुष ०

नमोविष्णुःभगवान्ॐःपुरुषंनमदक्षयः

मदभःक्रिद्विमेवनंभदक्षीॐमभव
मः १

यो मामजमनादिं च वेत्ति लोकमहेश्वरं
असंमूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ३

विवेकः॥

बुद्धिर्ज्ञानमसंमोहः क्षमा सत्यं दमः शमः

गी. १०

सुखं दुःखं भवोऽभावो भयं चाभयमेव च ४

शृङ्गिम: भभङउभिशुभुंपेमनंयमेयम:

भपीज विद्यति: मक्षीत्ति: उक्षीत्ति:

ठवत्रिठवक्रुङनंभङमवेयवविण:

भङ्गयमंभुप्रवेमङ्गेभनवभुख भ

भमीये भनभभङ्कल

ठवःख भङ्ङङ्ग:उख

नवेये मधुरा भा॥

ख॥

ङ्गवभनमङयधंलेकङ्गभ: भुङ्ग:

© Dharmarth Trust. Digitized By eGangotri

एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः

सोऽविकम्पेन योगेन युज्यते नात्र संशयः ७

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ८

गी. १०.१ इति मत्वा भजन्ते मां बुधा भावसमन्विताः ९

© Dharmarth Trust. Digitized By eGangotri

𑆱𑆑𑆳𑆱𑇀𑆥𑆾𑆫𑇀𑆥𑆾𑆟𑆑𑆠𑆾:

𑆃𑆱𑇀𑆩𑆴𑆤𑇀𑆤𑆱𑇀𑆩𑆴𑆤𑇀𑆤𑆶𑆥[illegible]𑆫𑆼𑆟𑆪𑆠𑆾: 𑆥𑆫𑆩𑆁

𑆃𑆱𑇀𑆩𑆳𑆢𑇀[illegible]𑆨𑆴𑆮𑆤: 𑆱𑆴𑆢𑇀𑆣𑆼𑆫𑆱𑇀𑆩𑆴

[illegible] 𑆤𑆴𑆫𑇀𑆮𑆠𑆪𑆳𑆠𑆴 ॥

𑆑𑆢𑆪𑆠𑇀𑆪𑆱𑇀𑆩𑆴𑆤𑇀 𑆩𑆁 𑆤𑆴𑆪𑆁 𑆠𑆥𑇀𑆫𑆮𑆠𑇀𑆠𑆴𑆩𑆫𑆩𑆠𑇀𑆠𑆴𑆩 1

𑆠𑆼𑆰𑆳𑆁 𑆱𑆠𑆠𑆪𑆶𑆑𑇀𑆠𑆳𑆤𑆁 𑆨𑆘𑆠𑆳𑆁 𑆥𑇀𑆫𑆵𑆠𑆴𑆥𑆥𑇀𑆫𑆮

𑆑𑆩

𑆨𑆑𑇀𑆠𑆴𑆪𑆶𑆑𑇀𑆠𑆥𑆫𑆳𑆪𑆁 𑆧𑆶𑆢𑇀𑆣𑆼𑆫𑇀𑆮𑆠𑆴 ॥

𑆢𑆢𑆳𑆩𑆴 𑆧𑆶𑆢𑇀𑆣𑆴𑆪𑆾𑆓𑆁 𑆠𑆁 𑆪𑆼𑆤 𑆩𑆳𑆩𑆶𑆥𑆪𑆳𑆤𑇀𑆠𑆴 𑆡𑇆

© Dharmarth Trust. Digitized By eGangotri

ॐ अथ भैरवस्तवक्रमप्रस्तुत भजभस्तुतस्लंतमः

नामयभ्रुमुष्ठवमुस्तुनमीपेनठमुड ११

मस्लनडवाम।

पंचकृत्यपंचाभ पविशंपरभंठवान

धनधंमास्वतंसिद्धभाःसिद्धेवभस्लंविदुं १२

गी.
१०३

वाभिपुरयां

शुरुभुभूषयभ्रवेमेवध्विनवमभुष

मभिडेमेवलेष्टुभः भ्रुयंमैवघ्वीधि

\मे ०३

भट्ट नमोविष्णुः भगग ॐ इति ॥

भवभेउम/ उंभट्टयक्रवमभिकेमव

नद्दिडेठांवनूक्रिंविरुमेवानमन

\कः ०५

पृकृवभाणत्रुति:

नमः

भुयभेवड्डनङ्कनं वेङ्गुरंधनधेङम ।
दुभेव भ्रैनैरनमयनःत्तुरे॥ स्नाभि

कुतुद्धम्क॥ कुतनिय तुः॥ मुनिहीमि पूकमक॥ विस्रयल क॥
कुठवनकुतेम सेवसेवयणगाद्धे ०४

तः मटक्तुतः यः
वतभद्रभृमेधे॥ स्मिष्टरुद्धविकुतयः

गी ०७ यिठविकुतिठिल्लकनिभं मुंष्टयुतिमुभि ०८

© Dharmarth Trust. Digitized By eGangotri

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तय
न् केषु केषु च भावेषु चिन्त्योऽसि भगवन्म
या ॥१७॥
विस्तरेणात्मनो योगं विभूतिं च जनार्दन
भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृ
तम् ॥१८॥ श्रीभगवानुवाच

ननु केनायं [illegible] विहितः [illegible]

ननु [illegible] यथा [illegible] कथयामि किंतु

धृतराष्ट्रेणैव [illegible] कथयति सञ्जय [illegible] ॥

धृतराष्ट्रः [illegible] ॥

[illegible] युद्धकामाश्च

धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः

[illegible]

गी॰ मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥१॥

००

किमर्थमुच्यते

सुमित्तनभद्दविध्नुदेवसिधंरविंसुभ ना

मस्रिउः धर ेभट्टे वभनेदुं धुकसक ंभट्टे॥ विसूद्दे धि गम्भियत्तेः

२७ भतउंवधुंन भट्टेभवीमि नभाद्मा॥ भत्युभत्नु ेर्नु॥ रह

भवीमिम्मनउभुम्मिनम्मेर ेभद्दममी १०

गानभधूदेेउिगभ ीयः भाभवेम॥ उक्तं

वेमनंभभवेमेम्मिमेवानभुम्मिव

धवउकभा क्षुउनंकदक्का ेठ्मेनधूभडनं भवः म्हूनमाग्नेः

ंत्रनंभट्टेमेउनवक्किः॥

उक्किया ेभनम्नू म्मिक्षुउनभुम्मिमे उन ११

© Dharmarth Trust. Digitized By eGangotri

रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसां

कुबेरः

अग्निः

वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ॥ २३ ॥

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम्

गी. सेनानीनामहं स्कन्दः सरसामस्मि सागरः २४

१००

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible] ३१

[illegible]

गी.
००३ [illegible] ३३

© Dharmarth Trust. Digitized By eGangotri

॰ गभूकागनं

मुनतस्नु: भिनंगानंवमश्यमभमं

मैखेभि (निविधञ्) गर मलमसञ्गर॥

॥ मंघस्नुनगास्नुरतिठेम

गर स्तिहृ ते॥ ॰ वियमं तुखडं मरो॥

पितृञ्भदृभमः भिमयुमः मंयमडु

म त्रिअपः / भडु ११

बमीडुखडंग

यडंव मद्दे॥

धक्कमस्नु: भिमैदनंकलः कलयाडु

भडुभा

भिंदः गनत्रः

नमगञ्
मदृ

भगाञ्मभहोमुड्डुवेनेउयस्नुपक्रिञ् १॰

© Dharmarth Trust. Digitized By eGangotri

पवनःपवडमभिमि नमस्कुमुहूडभनमा

पावयितृ ॐ वेगावडं वभष्टेव
मुभिमि॥ नमगत्रिः

भक्ष्मितं। भूवदेमकनं॥

नमः ॐ भकमन्मूम्भिम्मेडभमभिमक्र

मुवकम। दिडम्। मद

कवी ३०

भक ॐ भःमिनुडम्र मधुंमैवनमभुल्लन

मृयेचाम्निनेगुपि मुपमसुपुन वमस्तुवीडगाये:मिधूःमा२
पापम निं:कामुपेमृले: येगुरु येचाडनुनिलय
येहेकुःमुपकंम्रुपयडि मरम ठलः मडेमेमुभुव
मुकाकुषयडि नडमुपकंम्रु पय अडिकुडिहिःहः ३१।
डिभगी॰ विडमा नमकर्ष॥ वमम्लपा। विडमृनं॥

१०३

मघम्रुविमहविमुनं वमःपुवमडभनमा ३१

सममाग ण्ण भकुरेभिमरव्रुः मंभभिक

मकंरोद्दग्लीवःवममीरण्ण मत्रेधंवलंनंवृ ॥ भूम

धकद्वैनैकेवभ्रिुतः उषामम्रुतिः मकरेवेमचाव क्षै भमम

मेक्ष्मठिचुग्लभंन वक्रीननकुपाठवशीुति ॥

ध्रुकणभधग्ना

पाउमचवकम
ठलविपाउ ॥

ममव विभ्रुवेभापस्त्र
कुभ्रपिपाउव
क्रिंकु
भेहुरुं ३३ ॥

मकमेवुम्रयः कलेपाउंदविम्रुडेभ
।पः ३३

मचभंदव   मक्रुमयः

मह्रुः मचवदम्म्रुःदमकुवम्रुठविष्टंडं

ठविकल्लु ण्णंपुभिंभं ॥

कीत्रिःश्रीवग्रानवीण्ण मम्।उिमेपाप्रुतिः
।क्रम ३२

ममुम ममुरु
मुमष्टिरुम्रुःरुभ्र,
ठयपरुभुपान
दुग रमलेखु
विदुभिः ॥

© Dharmarth Trust. Digitized By eGangotri

यदन्द्धभद्वखभभ्रु गायत्रीभ्रुद्धभभद्

भभनंभनमीद्धि रुंभ गुंकंजभभक ३५

मुडकलयवभभ्नि वेन्नमुनल्भिनभ्रु

गी०
००२ यन्येभिद्वदभयेभि भद्दंभद्ववभद्रु ३७

© Dharmarth Trust. Digitized By eGangotri

कश्रीनंवभृमेवेश्रिपञ्जवनंपनाद्रूय:

येङ्गंद्रमभृभद्मिसाभि॥ द्रमेवभरिवद्गुतिः॥

भननसी लनंभट्टे॥ कुतमन्निनं भट्टे॥ भुरेद्रूभा॥

भनीनभपृद्रंद्रमः कवीनभृमनःकविः ३१

विवेकानंभट्टे विविकवना गुरुः

सभकतू ग्भा॥ स्रेतुभिस्तुतं

मन्त्रेमभयडभश्रिनीडिवश्रिरिसीधितं

गुरुन्नंगेपन केतुःभेनभ, वसभद्रसा॥ उद्रुन्निनाभा॥

भेनंमैवश्रियह्ननंस्नुनंह्नुनवडभद्रमा ३२

© Dhamarth Trust. Digitized By eGangotri

यस्तु पिभवक्रुउनं गीलंउमहुमभुल्न

भृरेडुंकरां
उड़ुः

नउम्भ्रिविनयक्तु मयक्रुंउमरमरभा ३७

मुउःभकल्रेन
वक्रुंनमक्रुउे॥

नतेभ्रिभमम्बित्नं विक्रुतीनंपरत्रय।

भज्ञ्यपउः

गी॰ रपयुउक्रुमउःपेउे विक्रुउेविभ्रुरेभया २॰

००४

© Dharmarth Trust. Digitized By eGangotri

𑆪𑆠𑇀𑆫 𑆯𑇀𑆫𑆶𑆠𑆴𑆱𑆁𑆫𑆩𑇀𑆥𑆁 𑆱𑆵𑆩𑆁𑆠𑆴𑆩𑇀𑆮𑆼𑆮𑆮 3

[illegible]

𑆠𑆩𑆼𑆮 𑆮𑆓𑆩𑇀𑆠𑆷𑆫𑆁 𑆩𑆩𑆠𑆼𑆁𑆱𑆩𑆩𑇀𑆟𑆮𑆩𑇆 20

[illegible] 21॥

[illegible]

𑆱𑆣𑆮 𑆮𑆕𑇀𑆤𑆼𑆠𑇀𑆫𑆼𑆤 𑆑𑆴𑆁 𑆱𑆷𑆤𑆼𑆤 𑆮𑆢𑇀𑆤𑆤

[illegible]

𑆮𑆴𑆰𑇀𑆟𑆷𑆢𑆩𑆴𑆁𑆱𑆁𑆤𑆑𑇀𑆫 𑆩𑆑𑇀𑆫𑆁 𑆩𑆼𑆤𑆴𑆠𑇀𑆫𑆼𑆫𑆁𑆓𑆁 23

© Dharmarth Trust. Digitized By eGangotri

उ॒ त्रिस्मीछगावस्नीउसुपनिषस्रुवऋविसु

यं येगामभेस्मीलक्षुस्लनभंवमेविकु।

उियेगोनभमरूमभेष्टयः ० मुस्लनउव

पवमुऋनि
मुभा॥

मुस्रनाऽस्रम विवेकविध
यभा॥

म त्रिभमत्वगुरूयपवभंगुहूभुष्ट्रस्रंभंस्ति

मुद्दंदत्ताग्उदट्टेउ मभंत
उट्टुस्मिरुभेविनस्मः॥

गी०
००७ ॐ यदुयेत्रुंवमभुनभेदेयंविगउभम ०

उ

© Dharmarth Trust. Digitized By eGangotri

अथ पूर्वे [illegible]

अथः पूर्वे [illegible] ॥

इन्द्रः कमलपत्राक्षः सहस्राक्षो [illegible] १

सहस्राक्षो [illegible] १॥

[illegible]

[illegible] ॥

[illegible] १

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

नउभंमह्रुमेहुभ्रु भ्रनैवभ्रुमन्नोधा मि

स्लोकिकं॥ स्नुनाइभ्रक मा॥ समभयेन सप्पाएिउपपए नमामर्हे॥

ह्रुंरूरूभिडेमभ्र: पमृभेयेगभेभ्रुरभा ३

॥भाष्यउवाच।

एवभुक्त्वाउउरूण भरूयेगेगन्त्रेदवि:

गी. ००३ सन्नयाभ भपाजयपरमंउपभेस्नुरभा ७

स्वा

© Dharmarth Trust. Digitized By eGangotri

𑆃𑆤𑆼𑆑𑆮𑆑𑇀𑆠𑇀𑆫𑆤𑆪𑆤 𑆩𑆤𑆼𑆑𑆳𑆢𑇀𑆨𑆶𑆠𑆢𑆫𑇀𑆯𑆤𑆩𑇀𑇅

𑆃𑆤𑆼𑆑𑆢𑆴𑆮𑇀𑆪𑆳𑆨𑆫𑆟𑆁 𑆢𑆴𑆮𑇀𑆪𑆳𑆤𑆼𑆑𑆾𑆢𑇀𑆪𑆠𑆳𑆪𑆶𑆣𑆩𑇀𑇆

𑆢𑆴𑆮𑇀𑆪𑆩𑆳𑆬𑇀𑆪𑆳𑆩𑇀𑆧𑆫𑆣𑆫𑆁 𑆢𑆴𑆮𑇀𑆪𑆓𑆤𑇀𑆣𑆳𑆤𑆶𑆬𑆼𑆥𑆤𑆩𑇀𑇅

𑆱𑆫𑇀𑆮𑆳𑆯𑇀𑆖𑆫𑇀𑆪𑆩𑆪𑆁𑆢𑆼𑆮 𑆩𑆤𑆤𑇀𑆠𑆁𑆮𑆴𑆯𑇀𑆮𑆠𑆾𑆩𑆶𑆒𑆩𑇀𑇆

𑆢𑆴𑆮𑆴𑆱𑆷𑆫𑇀𑆪𑆱𑆲𑆱𑇀𑆫𑆱𑇀𑆪 𑆨𑆮𑆼𑆢𑇀𑆪𑆶𑆓𑆥𑆢𑆶𑆢𑇀𑆡𑆴𑆠𑆳

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

पत्राभिमेवं भुवमेवमेदे मवं भुष कु

प्रचरवभुभ्मर नपत्राभीति वतुमनेदेः गग्राह्मीनभप्रदंस्न॥

पपाति:॥

ऊर्घलेकवर्तु नभो॥

विमेषमह्ना वृंश भीमंकमलम कमलमन ऋषीपद्म कालिकयं मोक्षिभा यस्तूनाति मह्ममनभं॥

भस्लेकवर्तिनः मूर्धवनवर्तिनः॥ तेनच्च कृपाश्रिकुवनंलीनं प

नमु मर्धीस्नमवर्त गांभ्रमिद्रना ०५ । त्राभीतिभ्रुजठ वंभुतिपंमितवना ।

मपर्दवजाभुम ना

मनेकवक्रमुरवक्त्रनेदं पत्राभिद्भवडे

मवगाउ कृता॥

नत्रुपभा नातुनमहंनयनभुवतुं प

मभ्रपनस्व यमुति मङ्गम ता॥

त्राभि विमेस्रवित्र कृपभा ०७ ॥

© Dharmarth Trust. Digitized By eGangotri

किरीटिनं गदिनं चक्रहस्तमिच्छामि त्वां
द्रष्टुमहं तथैव तेनैव रूपेण चतुर्भुजेन
सहस्रबाहो भव विश्वमूर्ते ॥ ४६ ॥
मया प्रसन्नेन तवार्जुनेदं रूपं परं
दर्शितमात्मयोगात् तेजोमयं विश्वमनन्तमाद्यं
गी. ११ यन्मे त्वदन्येन न दृष्टपूर्वम् ॥ ४७ ॥

© Dharmarth Trust. Digitized By eGangotri

[illegible] मन्त्रवीरं मन्त्रराजं स

[illegible]

[illegible] ९

[illegible]

[illegible]

[illegible] १० ॥

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible] ११ [illegible]

[illegible]

[illegible]

[illegible] १२

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

वक्त्राणि ते सुरभाणि विभाति संमुखं ल

निठ्यानकानि केसिद्धिलग्नमसन

तेषु भक्तसुतेमुखितैनतुभाषितैः ३१

यषानलीनं वदनेषु वेगाः भभक्तमेव

ठिभापसृवाति उषातवभीनगलेक

वीर विभाति वक्त्राणि ठिवि... ति ३३

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

कथय [illegible] पुरुषं

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

लोक [illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

एतस्क्षर्वमनंकेमवम्र् नत्ताजुलिवेप

कस्मान्नः॥

पद्मः भम्यतीनु हसुः॥

भानः किरीटी नभभूतक्रयास्वा हन

कष्ट कस्मात्भवति॥

क्षुं भगान्नसंठीडठीडः धुम्भृ ॐ मक्त

एतस्मृतोक वति॥ कीर्तनेन धुकेषं॥ गंधधूपे ति॥

नडवम भुनेहृधीकेमउवधकीहृद्य

मन्तरागं यिपेति॥

गङ्गहृष्टज्ञारमृत्तेम रक्तं भिठीडनि

पलायते योगउपेभक्तः संम क्रिभिक्षुं थुं॥

क्षिमेहृवति भवेनभमृत्तिभभिक्षुमदुः ३७

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

आपत्रि मन्त्रधुमण्ठयत्नं देवक्ष्ठदे।

यस्य देवमापत्रि मस्नतमादिमानं

डवेसुं मयाधुमसन्त्र्युयेनवाधि २०

यस्मवदमडमभमस्त्रुमि विदरम

यः मनहेरानेव [illegible] धवधुमसुसडम

गी. ९९ मं [illegible] मयोडमडमधुमयमा २१॥

© Dharmarth Trust. Digitized By eGangotri

पितृभिर्लोकस्थमात्रा मातृस्थ ब्रह्मस्थ [illegible]

स्वर्गगतजीवा तत्र [illegible] :।

[illegible] लोकद्वयेषु पुत्राभ्य [illegible] २७

[illegible]

मातृभीः पितृभीः [illegible]

[illegible] ध्रियाय [illegible] २८

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible] २५ [illegible]

[illegible]

[illegible]

गी. [illegible] २६ ॥

०३१

© Dharmarth Trust. Digitized By eGangotri

श्रीभगवानुवाच अथ धूमवेनकवाजलनेमं

ममपि धूपपत्र चानुमी॥

धूपं पंचाम्लिवभागेयगाव वेलमथंविस्र

धूपम ततागमूतेन॥

भजन्तभागं यमेनमूतेननमध्धूपचमा री

वेमयझ विमूयनैः॥

नवेमयझ्यमैनैवमनै वमछियाति

मन्त्रय मिदिः॥

उपेठिनो ः एवंधूपःमहभगंचललेके

धूपमहवामूतेन॥ व्यं

सखं बमूतेनजन धूपवीर ३३ भवेदूष

© Dharmarth Trust. Digitized By eGangotri

अमविमुक्तचे स्पर्भुक्तुपंपेरभीस्य
शुपगाउठयः भुमद्रामितुम्न॥
ञुमितुमा शुपेतठीः धीतभनः धनमु
तस्रुवमेतुपमितुसु धपनु १७ मान्नयउव
उषैतिउक्तु॥
उदूलनंवभुम्देवभुषेतुः भकंतुपमस्काय
भभक्तुयः शुस्र भयभमभमठीउभेनं ञुठ
भनेगभमसगीगः विसुतुपःदेपलगुडिव॥
धनःसेसुवधमदष्ठ १० मनलनतवाम।

शुवकिम्तुपंकि गीदमे ... स्यतुपःसमत्तु लियुत्ता ... सीवमे ठवनम लपीउभुर सिसोठि मस्नय मम॥

गी. ११३

स्पष्टं सम्भावयन्तं रूपं उदभेदं स्फुरन्नूतन उत्तम

स्वयं भास्वरः धूम्रवर्णाभिषः श्यामलवं

नीलं श्यामं वपुः सुमेरुः धृतशिरस्त्राणः ५०

विश्वरूपं उदंसस्वनसंव सर्वांगभूषितः वलनधनः पद्मस्थितः ॥ श्रीभगवतस्तवम् ॥

सर्वसत्त्वाभिरूपं स्पष्टवर्णाभियन्तम

मेघवर्णप्रभं रूपम् विहंगमनकाल्मषः ५७

© Dharmarth Trust. Digitized By eGangotri

नाहं वेदैर्न तपसा न दानेन न चेज्यया

शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ५३

भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन

गी. ०१३ ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परंतप ५४

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

𑆑𑇀𑆬𑆼𑆯𑆾𑆣𑆶𑆑𑆠𑆫𑆱𑇀𑆠𑆼𑆰𑆳𑆩𑇀 𑆃𑆮𑇀𑆪𑆑𑇀𑆠𑆳𑆱𑆑𑇀𑆠𑆖𑆼𑆠𑆱𑆳𑆩𑇀𑇅

𑆢𑆼𑆲𑆳𑆨𑆶𑆩𑆳𑆤𑆶𑆤𑆂𑇆

𑆃𑆮𑇀𑆪𑆑𑇀𑆠𑆳𑆲𑆶𑆓𑆠𑆶𑆫𑇀𑆢𑆷𑆂𑆒𑆁𑆢𑆼𑆲𑆮𑆢𑇀𑆨𑆶𑆫𑆮𑆳𑆥𑇀𑆪𑆠𑆼 𑇕

𑆱𑆩𑆫𑇀𑆥𑇀𑆪

𑆪𑆼𑆠𑆷𑆱𑆫𑇀𑆮𑆳𑆟𑆶𑆑𑆫𑇀𑆩𑆳𑆟𑆶𑆩𑆪𑆶𑆱𑆁𑆤𑇀𑆪𑆱𑇀𑆪𑆩𑆠𑇀𑆥𑆫𑆳𑆂

𑆍𑆑𑆳𑆤𑇀𑆠𑆨𑆑𑇀𑆠𑆶𑆪𑆾𑆓𑆼𑆤𑇆

𑆓𑆵· 𑇑𑇓𑇐 𑆃𑆤𑆤𑇀𑆪𑆼𑆤𑆽𑆮𑆪𑆾𑆓𑆼𑆤𑆩𑆳𑆁𑆣𑇀𑆪𑆳𑆪𑆤𑇀𑆠𑆇𑆥𑆳𑆱𑆠𑆼𑇅

© Dharmarth Trust. Digitized By eGangotri

ॐ अभङ्गम भङ्गुरु भङ्गम्भर भगवत्।

भङ्गम्भर भगवत्स्मर स्मरत्भभङ्गू त्र भभङ्गुरु भङ्गुक। स्मनयभेन उत्तजङ्गुभवर्व त्रयव्रिकुङ्गु स्मि। भङ्गू तद्विवयिडस्त्रुनव स्मृतुस्त्रनकव स्मि॥१॥

ठवाभिचामिरद्रुत्र भद्वावामित्रमेतभभा ॥१॥

भकल्पद्रुक भनः स्मुरौज॥ वद्भित्रिभुय स्मिक॥ भुवेमय

भद्वैरभनकुण्डु भयिवक्रुं निवेमय

भदतुभमद्रुम वर्ष नवभंकविश्व स्मि॥

निवाभिश्वभिभद्वैर भत्रजङ्गुनभंमयः ३

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

म्यैषेङ्मधूम्मजेभिकवुंभक्षेगाभ्यु म्रिउः

यमि
भवेधंभ्यधुर्जनमः यमूकनंम कम् भद्रि हेङ्मीनं ठलानियउ भग्वेकंकम ... भ्युम्रिउः उहि
म्रिउकुदु धविधूम॥

भवकम्भठलहृगं उउःजमयउङ्मवना ०।

हुनभ्रुवमङ्मः हृमङ्मुयः महभम्रु रहुलहूगं रुमहून हुनंठगवमयहुवि म्रिहुउ विमेधयाउ॥

मेयेधिहूनभहुमभहूनहुनंविमिहुउ

प्रृनेनठगव मयहुनकमठलानि भहुभिउयूनुउ कमठलहृगेन मङ्हिकीमङ्गिः भरा ।।०४॥
मङ्गिः

भ्रनहुकमठलहृगभुगामुङ्गिनङ्गरभा ०५

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

यो भक्तो लाभेन न हृष्यति ॥ यो भक्तो न द्वेष्टि ॥ न शोचति ॥ न काङ्क्षति ॥

ये न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति

पुण्यपापपरित्यक्तुं शीलं यस्य ॥

शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः १७

स भक्तः ॥

समः शत्रौ च मित्रे च तथा मानापमानयोः

द्वन्द्वविषयेषु समः स्नेहशून्यः ॥

गी. १८२ शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः १८

© Dharmarth Trust. Digitized By eGangotri

उलृनिद्मन्तुडिम्नेनी मतुध्रुयेनकेनमिश

नियउवम मुद्रः॥ अंयउव का घ षाल ब्रुन॥

ग्नकेउःभ्रुमउिठक्षिम म्नेधियेनवः ११

मनउिभ्रुडि॥

येउणमभउभिमुंयेषक्षेपड्पभउ मु

उमभक्षुभुकं पम्मस्वभ्डमुलु उमपनहूउ॥

म्नणन्नभद्वभणक्तमेडीमेधियः १०

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

षट्कोणं यत्स्वयं भूतं यन्त्रिकं त्रिकोणं स्वयं तं म

[illegible]

मध्ये यद्धृतं वर्द्ध सम्पूर्णम् भेदम् भेद २ ८

[illegible]

वभिश्रुर्लिखितैः ॥

क्षितिर्वरुणाग्नी मुख्यौ विविधैः पञ्चका

[illegible] ॥ ५ ॥

वृक्षमूलपञ्चभिर्देवतास्थि विनिर्मितैः ५

गी
७३

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

सघटन्मङ्गलानिष्टवंतद्ध्वङ्गलानृतमसत्त्वनमा ०३

निष्टल्पवः उद्धङ्गलनभृतः धृयेलल्नं भेक्तभृभृमज्जनं भवेद्गृह्यङ्ग्लेमनभा॥ मवेद्गृष भृत्क्विपवीतं॥

ङ्गलनमितिथेक्त मङ्गलंयमतेद्गृष ०३ ङ्गल

भेक्तंधृधेत

यंयतद्धवकृभि यङ्गलवृभठभमत्ते म

विधिनिषेधयोग्यविषयम।

नास्मिभद्धंयुक्तं नमद्गृभठङ्गमृते ०३ ॥

यी० ०३५

०३

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

यस्तोमनंतपःकर्मनदृष्टुंकदमेवउञ

पवननिमित्रं मुद्रिकर्मा॥ मनीषिणं विवेकवताम्॥

यस्तोमनंतपश्चैवपवनानिमनीषिणं ४

[illegible] मंद्रंकत्सुसुलि निवंस॥

तउत्सृपिउकर्मणिमग्नंदृक्कोउलानिम

मृउगव

कउहर्णीत्रिमेपजानिक्लिंतंमज्मुउमम्मा ७

मृउा

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible] १

[illegible]

[illegible]

[illegible]

[illegible] ३

© Dharmarth Trust. Digitized By eGangotri

कदभिहेवयक्कमनियउंक्तियउल्लन
वक्ष्ट मुवस्तृकं

भंक्षंटक्षाठलंमैवभटगःभाद्विकेभउः ७

मजमलंमुःापवृंद
स्मिसिंर मुःमनमि
नक्षिषि॥
जमले भापकोसि
पुये भइटकमनसे
नउपस्तउ॥०॥

नदेभूजमलंकमजमलेन,उपक्ष्टउ

भठुन
भंस्तृमुः भिउभउः॥

हगीभक्ष्मभाविम्भेमपवी,किवभंमयः ०

म॰ दिल्ली
ह॰ वी

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

यौव्रुमं निभजव देकार निविवेणभे

भहेतत्तेभेक्ष निभिक्षुयेभवकभं ०३

मणिभुनं उषकत्तुकारं मधपवाग्रिणभ

विविपम्नुपषक्रे भुमैवभेप्रारयाम्रकं ०२

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

स्तुनंकममकत्तुमद्दैवत्र ठकतः

गु मांह तेत्रु तेनं म एनविमोचयर स्तु ३२ मन्दृ॥

भमूका

भेमृत्रे भमुनेयषवमू उत्तुपि ०१

यक्ष दिमुवरत्तेषु॥ येनस्तुनेन॥ धमभजस्तुतुं निचिकामा॥

भषक्तुतेषुयेवैनंकठवमृद्दयमीकृते।

मत्तभुं

गी.

०१८ मविठ्ठौवितठ्ठोषठस्तुनंमाहिकंमा ३ ९०

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible] १०

[illegible]

[illegible] ११

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible] ११

[illegible]

[illegible] १२

०७५ [illegible]

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

𑆪𑆡𑆳 𑆥𑆢𑇀𑆩𑆁 [illegible] 𑆩𑆑𑆫𑆤𑇀𑆢𑆁 [illegible] 𑆩𑆑𑆫𑆤𑇀𑆢𑆩𑆼𑆮 [illegible]

𑆪𑆡𑆳 [illegible] 𑆱𑆴𑆢𑇀𑆣𑆴𑆂 [illegible] 𑇓𑇐

[illegible]

𑆓𑆵॰ 𑇐𑇑𑇑 𑆨𑆮𑆘𑆳 𑆮𑆴𑆥𑆫𑆵𑆠𑆁 [illegible] 𑆱𑆴𑆢𑇀𑆣𑆴𑆂 [illegible] 𑇓𑇑

पश्ययपकायउभनःधृ~द्मियद्विपः

उस्कुभ्र् वृक्षेउवि् मृ~क्षि॥

मिठ्ठेकणे~विमयद्रुभणयद्द॥

येगेनृशूठिमवे~पाउिःभपजभाशि

निंश्कउवृउय

वणयउि॥

पाः

की ३३ ययउपमकभ्ज्क्नूश्णयउे

भणश्रुनभङ्गेन॥

श्लन भ्रभङ्गेनठलाकमूीपउिःभपजर

।णमी ३५

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

गी. ०७३

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

मेरुदेवेभ्योऽग्रिमं ग्रंथं ... ध्रुपलयते

पग्रत्र भः ध्रुग लक्ष्मी पैरं केमले सपरस्मापङ

रुक्षः निर्यमन मतिं

मनभीस्त्रठवस्मम ३कमस्मठवलभा २३

कद्ध रुलगुय निनर्गां सयविस्मयामिङभीस भुक्तरत्तुत्रभंनीयभा

नधिगेरमवा ल्पैवेशकमस्मठवलं

"इवल्पिक सबक्कुपभा"

वी. पविमदस्मकंकमकुसशुपिस्मठवलभा २२

०५०

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

𑆯𑇀𑆫𑆼𑆪𑆳𑆤𑇀𑆱𑇀𑆮𑆣𑆫𑇀𑆩𑆾 𑆮𑆴𑆓𑆶𑆟𑆂 𑆥𑆫𑆣𑆫𑇀𑆩𑆳𑆠𑇀𑆱𑇀𑆮𑆤𑆶𑆰𑇀𑆜𑆴𑆠𑆳𑆠𑇀

𑆱𑇀𑆮𑆨𑆳𑆮𑆤𑆴𑆪𑆠𑆁 𑆑𑆫𑇀𑆩 𑆑𑆶𑆫𑇀𑆮𑆤𑇀𑆤𑆳𑆥𑇀𑆤𑆾𑆠𑆴 𑆑𑆴𑆬𑇀𑆧𑆴𑆰𑆁 𑇔𑇗

𑆱𑆲𑆘𑆁 𑆑𑆫𑇀𑆩 𑆑𑆿𑆤𑇀𑆠𑆼𑆪 𑆱𑆢𑆾𑆰𑆩𑆥𑆴 𑆤 𑆠𑇀𑆪𑆘𑆼𑆠𑇀

𑆓𑆵𑆂 𑇐𑇓𑇐 𑆱𑆫𑇀𑆮𑆳𑆫𑆩𑇀𑆨𑆳 𑆲𑆴 𑆢𑆾𑆰𑆼𑆟 𑆣𑆷𑆩𑆼𑆤𑆳𑆓𑇀𑆤𑆴𑆫𑆴𑆮𑆳𑆮𑆸𑆠𑆳𑆂 𑇔𑇘

© Dharmarth Trust. Digitized By eGangotri

ॐ

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible] ५०

[illegible]

गी. ०३१ [illegible] ५१

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

उँतिहक्षुनमुपृउंगप्रहुनुरुजंभय

उपाक्षिप्तं मजिरमं भयाभयश्लेन

यश्लेस्त्र नीउस मूर्भा॥ भवभकर्मा॥ केन॥

विभ्रष्टेउम्रन्मेषे॥ यषस्फ्रुमिडषज्ञन १३

पउभ्रिमप्रद्र लेमिउमउि उवमेन निव श्रिसृउ उंउ १३॥ ष्ठवः

भवेष्ठपिप्रुहे ष्टुप्रुहउभभा॥

उहउरुक्रुभूधि॥

भवप्रहउभंक्रयःम/ रभेपवभंवमः

भिप्रः मश्रुभा

नी: ०३५ उंभ्रुमिमेम/मशमिउिउवक्रामिउदिं १२

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन्

[illegible]

[illegible]

अनन्यचेताः सततं यो मां स्मरति नित्यशः ।१

[illegible]

[illegible] ।२॥

[illegible] ।३

[illegible] ।३॥

गी. ०३ [illegible] मामेवैष्यस्यसंशयः ।३

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible] ॥

[illegible] १५

[illegible]

[illegible] ॥ [illegible] ॥

गी. ०३३ [illegible] १२

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

यत्र योगेश्वरः कृष्णस्य ॥ इति श्रीभगवद्गी

[illegible]

तासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे

[illegible]

श्रीकृष्णार्जुनसंवादे मोक्षसंन्यासयोगो नाम

[illegible]

गी· ०३७ [illegible] ७ [illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह

सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते २४

ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना

गी. ०१०

अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे २५

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम्

निर्विशेषं

[illegible]

विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति २७

[illegible]

समं पश्यन्हि सर्वत्र समवस्थितमीश्वरं न

[illegible]

गी. ०२५ हिनस्त्यात्मनात्मानं ततो याति परां गतिम् २८

[illegible]

०३

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

मन्त्रमिन्द्रविन्तु॰ रुद्रमन्त्रयमन्त्रय:

मरीचिभिःपिकेतेयनकेरैणालिप्स्तु ३३

यथा भवगाङ्गेभैरुमकमनेपालिप्स्तु

नी॰

०२३ भवद्भिर्मिर्मेदेऽषम्भनेपालिप्स्तु ३३

© Dharmarth Trust. Digitized By eGangotri

यघ धकमयरेक: नङ्गुलेकभिभुंगविः

ममङ्कह्वे येनभ्रीटुक्कम मध्ध्रूनेजौनो मूकमङ्कस्थ्रू कम्रुणमेनयङ्गते ७ऽऽविम्भध्रुते नद्रुयवेऽ॥३८॥

मेअंकेशीडघनङ्गुधकमयऽठिरड ३८

केसंविवेकझूत लज़लेन॥

मेरमेइङ्करयेरेवभङ्गुरंझुनमम्रूध झ३

येयभङ्गाझ्ड नंधूनऽभिमुर्थः भकमर्क्षमं भेवीर्प ऋह्वनमिकम येविम्भ्रूते पंयपसं यवि॥३९॥

धनऽिभेसंम येविक्र्द्ऽिडपगभा ३९

© Dharmarth Trust. Digitized By eGangotri

ॐ इति श्रीभगवद्गीतासूपनिषत्सु ब्रह्मविद्

यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे मोक्ष

संन्यासयोगो नामाष्टादशोऽध्यायः ०१८ श्रीभ

गवद्गीता [illegible]

[illegible]

[illegible] ०१८

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

श्रुत्यिक मल्लिवि प्रकस्मकं हस्थं ।   मवेय द्रवदहिदं   मउ

ग्रमबं निम्नलवूदृकमकमनभयभा

भ्रापमक्नेनवप्राउिम्नमक्ने नमानथ १

गनेकगाहृकं विद्विरथ्नमक्नमम्रुकवभा

उत्रिवप्राउिकेत्रेयकम्नमक्नेनमेदिनभा १

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

ग्ल्तुभक्ष्मः ठिकृयभर्द्वठवठिठव ३ ग

जिभूर मृत्युवमारुवठि

उद्भवठि॥ मृठिकृय॥ उद्भवठि॥ मृठिकृय॥

ग्ल्मृवंउभस्त्रैवउभमृवंग्लभुघ ०॰

मक्षुमिष्णुनः मृक॥

भवङ्गेघमेदेभ्मिच्क्रकमउपलयउ

उउमकन्नुपमि लिङ्गिनपिरनी यम्हिद्रुक्ः॥

क्ष्लंयमउमविहृङ्विवकृंमवभिद्दुउ ०॰

॥

© Dharmarth Trust. Digitized By eGangotri

[illegible]

कर— मीलहं   मं कल्प... गमः॥   कर्मत्र विषय

लोकस्विकं कुर्मणैव ... मन्त्रस्यते॥

[illegible]

विवेकहूंसः

मनस्मः॥   ...कहुहूगन ... भ...नक्रिदभ ... मैदोभहाठिनि वैमः॥

[illegible]

गी. ०२१   [illegible]

© Dharmarth Trust. Digitized By eGangotri

𑆪𑆫𑆶𑆩𑆢𑇀𑆮𑆼𑆥𑆠𑇀𑆫𑆁𑆢𑇀𑆮𑆼𑆠𑆥𑆬𑆪𑆁𑆪𑆠𑆴𑆩𑆼𑆢𑆲

𑆩𑆢𑇀𑆮𑆼 𑆥𑆿𑆠𑆴 𑆪𑆵𑆮𑆂

𑆥𑆬𑆱𑇀𑆪 𑆱𑇀𑆮𑆤𑆁 𑆱𑇀𑆮𑆩𑆵𑆤𑆩𑇅

𑆓 𑆠𑆩𑆼𑆠𑆩𑆮𑆴𑆩𑆁𑆱𑇀𑆬𑆼𑆑𑆤𑆩𑆬𑆤𑇀𑆢𑆶𑆠𑆴𑆥𑆲

𑆥𑆿𑆠𑆴

𑆩𑆳𑆬𑆁 𑆑𑆩𑆳𑆩𑆠𑆼𑆥 𑆩𑆠𑆱𑇀𑆪𑆱𑆴 𑆱𑇀𑆪𑆁𑇅

𑆠𑆼 𑇑𑇕 𑆩𑆬𑆴𑆩𑆴𑆥𑆬𑆪𑆁𑆓𑆢𑇀𑆮𑆑𑆩𑆩𑆳𑆑𑆴𑆱

𑆩𑆠𑆂 𑆥𑆠𑇀𑆫𑆴𑆩𑆴𑆱

𑆱𑇀𑆪𑆥𑆼𑆠 𑆠𑆱𑆥𑆬𑆵𑆤𑆱𑇀𑆮𑆩𑆩𑆴𑆩𑆿𑆑𑇀𑆪𑆼𑆤𑆴𑆱𑇀𑆮𑆫

𑆪𑆠 𑇐𑇕

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

विवेकी

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

ਪ੍ਰਕਾਸੰ ਸਪੂਰਨ ਤਿੰਨ ਮੇਦ ਮੇਰ ਸਮਧਾਨ੍ਰਵ

ਪ੍ਰਵਿਰਤੇ ਮਹੁਕਾਂਦ ਕਾਲਾਂ ਕਾਂਦੋ ਤੇ ਤਮਾਂ ਕਾਂਦ

ਸੁਃਖ ਵਸ੍ਤੂ ॥ ਸ੍ਰੁਤਃ ਧਾਮ ਨਿਸਤਿ ॥ ਸ਼ਾਪਰਸ੍ਤੂ ॥

ਨਰੋਤ੍ਰਮੁੰ ਸਪੂਰਨ ਤਾਨਿ ਨਾਨਿ ਉਤਾਨਿ ਕਰਮਾਣਿ ੧੧

ਸ੍ਰੁਤ ਪਾਤ੍ਰ ਧਰਮ ਹੋਤੇ

ਸਾਕ੍ਰਿਤਯ ਸ੍ਰੁਤਃ ॥

ਤਸਮੀਨਰਸਮੀਨੇਤੁ ਮੈ ਦੇਨ ਵਿਸਮਹੋਤੇ ੧

ਤਾਤ੍ਰ ਸਰਸ ਪ੍ਰਕਾਰ ਯ ਕਰਤੇ ਸੰਸਮ ਸਮ੍ਰਵਿਤ੍ਰਨ ਸ੍ਰੀਤਿ ਵਿਵੇਕ ਸ੍ਰੁਨੇਨ ਯਦ ਸ੍ਰੁਤ ਸ੍ਰੁਤੀਸ ਧਰਮ ਕਰਿਆ ਨਿਸ੍ਰਿਤਃ ॥੧੨॥

ਪਰਤ੍ਰ ਉਦੈ ਯਯਰ ਸਿਧੁਤਿ ਨੇਨੇ ਤੇ ੧੨ ॥

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

ततः परं तत्त्वविभाजितं [illegible]

वस्तुविकल्पः [illegible]

यतः [illegible]

[illegible]

विनिवृत्तकमः [illegible]

निवृत्तः विकल्पः॥

[illegible] ५

© Dharmarth Trust. Digitized By eGangotri

नउन्तभयतेभ्रदेनममसाकेनपावकः यन्न
भदं भ्रकमयति॥

इन्ननिवडन्ते उन्नभपरमंभभ । भ

भमैवपाभः निरंसभ्रधिभयपाकल्पिउः भ्रटस्ट्रेवसन्ले
नउभउव पान भ्रधकेनव नेमउवंमः॥१॥

भेवंस्मेमनीवलेकेमनीवकुउः भनाइनः

भंमारे केवाक
भः कन्नति॥

गी.
०५३ भनःधभ्रनीमियानिभ्रनउिभ्रनिकम्नति १

०५

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]॥ [illegible]

विवेकिनः॥

मा [illegible] ॥०॥

[illegible]

[illegible]

यत्र ये योगिन[illegible]

[illegible]॥

चाविवेकिनः॥

गी. [illegible] यत्र [illegible] ॥००॥

[illegible]

© Dharmarth Trust. Digitized By eGangotri

यस्मात्सिद्धिर्गणेशे स्मरणात्तु भयं नोऽपि लभ
यस्मात् सिद्धिः सिद्धिं यं अनेकप्रकारां गणेशे विघ्नं प्रकामयति तस्मै भजीय ... ॥०१॥

यस्मात्तु भीमभयं मृत्योर्गणेशे विघ्नभञ्जकं ०१

यामादौ विघ्नसमूहान् निर्गमयन्तु मे सम्भ

यस्तु भीमक्षणी ... मे मे ... ०१

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

द्रुविमेधुनधे लोकेकारम्नः कार मेवम

धुनधः [illegible]

कारः भवा [illegible] निक्रा [illegible] ०१ [illegible]

[illegible] विलक्ष:

उतमः धुनधमुहूः धरमा [illegible]

[illegible] गँमनमीलः यक्षं ना ३

येलेकश्यमः विमृ विक [illegible] पाँस्वरः ०१

© Dharmarth Trust. Digitized By eGangotri

यस्मात्क्षरमतीतोहमक्षरादपि चोत्तमः

[illegible]

अतोस्मि लोके वेदे च प्रथितः पुरुषोत्तमः १८

[illegible]

यो मामेवमसंमूढो जानाति पुरुषोत्तमम्

[illegible]

गी० १५५ स सर्वविद्भजति मां सर्वभावेन भारत १९

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

मविवेक:

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible] 1

[illegible]

[illegible]

[illegible]

[illegible]

[illegible] 3

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible] ९

[illegible]

गी. ०५३ [illegible] १०

© Dharmarth Trust. Digitized By eGangotri

𑆱𑆴𑆤𑇀𑆣𑆶𑆩𑆣𑇀𑆪𑆼𑆩𑆼𑆪𑆁𑆱𑇀𑆡𑆬𑆪𑆁𑆠𑇀𑆫𑆩𑆶𑆯𑇀𑆫𑆴𑆠𑆂

𑆩𑆫~𑆩𑆼𑆫𑆶𑆂𑆠𑆼𑆪𑆱𑇀𑆪 𑆩𑆶𑆩𑆾।

𑆮𑆴𑆣𑆼𑆪𑆼𑆥 𑆑𑆼𑆤𑆳𑆥𑆴 𑆪 𑆱𑆥𑆼𑆮𑆼𑆪𑆁 ॥

𑆑𑆩𑆜𑆥𑆸𑆶𑆟𑇀𑆜𑆼𑆤𑆳𑆓𑆥𑆳𑆯𑆩𑆳𑆫𑆶𑆣𑇀𑆮𑆳𑆯𑇀𑆫𑆴𑆠𑆴𑆤𑆴𑆫𑇀𑆩𑆴𑆠𑆂 𑇑𑇐

𑆯𑇀𑆫𑆵𑆣𑆶𑆫𑆴𑆑𑆳𑆢𑆴 𑆬𑆑𑇀𑆰𑆥𑆳𑆤𑆴𑆱𑇀𑆩𑆶𑆫𑆴𑆠𑆬 𑆥𑆼𑆮𑆁 𑆱𑆩𑆥𑆴 𑆓𑆠𑆵𑆠𑆂 ॥

𑆱𑆶𑆩𑆳𑆥𑆩𑆩𑆁𑆤𑆮𑆽𑆂𑆑𑆩𑆜𑆼𑆥𑆼𑆥𑆫𑆪𑆠𑆂

𑆇𑆱𑇀𑆩𑆸𑆠𑆴

𑆩𑆼𑆢𑆳𑆯𑆴𑆤𑆳 𑆥𑆤𑆫𑆩𑆵𑆤𑆳।

𑆪𑆁𑆢𑆼𑆑𑆩𑆜𑆤𑆳𑆓𑆁𑆩𑆶𑆱𑇀𑆛𑆳𑆪𑆼𑆤𑆓𑆩𑆳𑆭𑆳𑆪𑆤𑆳। 𑇑𑇑

© Dharmarth Trust. Digitized By eGangotri

रु१ः

ॐ स्रभ्रुभयालह्रुभिस्रुंध्रुध्रेभनेरवं
भनम: ध्रियं

ॐ स्रभ्रुभ्रीस्रुभ्रुधिभेठविश्रुउिधनचनभा ०३

स्त्रनुथ
स्रीतंश्रुभी॥

भ्रुभेभयाक्रः मह्रुद्रविश्रेमर्पगनुधि

स्तनुद्रं॥

गी॰ ८
०१७ रंस्रोड्रुभ्रंक्रोगीभिक्रुंरुवलवश्रुापी ०२
॥

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

शिविपंनरकमेर्मु स्वरंनमनभङ्गनः क

उक्तानभः भूमेक्षा
मेरे भकलमेधभुल
कुंडेधरंय
अवधु धविवल्लनीय
सिद्धुःसीव
दभिउ १०॥

त्रिणधकं नीमयेनिभूपकं॥

भः रेणभुषलेठभुभ्रमेऽरुयंरुलेग। १०

॥

नरक

स्यैविभक्तः केत्रेयउभेद्रवेभ्रिठिज्ञः

॥

मूंय:भापनं
उपेयेगाकि॥

गी. ०१०

सुमरद्कृनः मूंयभुउयाउपरंगाउिभा ११

०५

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible] 13

[illegible]

[illegible]

[illegible]

[illegible] 14

[illegible]

© Dharmarth Trust. Digitized By eGangotri

ॐ श्रीभगवद्गीता [illegible]

[illegible]

[illegible] ॰ १ ॰ [illegible]

[illegible]

गी॰ ७१ [illegible] ॰ श्रीभगवा[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

भक्षपत्रं विगाश्मश्रं सनवं भिन्नत्तु
पत्रभो

यत्प्यभंङ्गुत्वमंप्राडिपड्विधिंतंमयस्

मनुक्तु: वसिष्ठं ॥ १

उस्मिभुभ्रुधिस्म:भेरुंठेस्मनंतंभमधि

मनसं कलानुजि
विषमपुव
भग:सिभंभ
कलानु: ॥

सम्भूतुमायतः
यस्तु: मृतभीयते ॥

यं ०: मनलाकस्मिविदसोविणिम/धु

यस्तुभुतं
करुमुरनान्हु
हे भणनीयभिकेरं
भनमक

मकागुत:

यंसु:

यस्तुसे यमुरुमेवेडिभनः भभमाय
भभंपुक: ००

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

मनःप्रसादः सौम्यत्वं मौनमात्मविनिग्रहः

भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ॥१६॥

श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः ।

अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ॥१७॥

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

उभयेषामपि कुर्म्हयस्मिन्नुपः क्रियः

ध्वत्रे विपन्नेत्रः भउंघक्षवाम्निनाभा १२

उभिद्यछिभद्धयथलंयस्मिन्नुपः क्रियः

गी. ०१३ मनात्क्रियस्त्रविविपः क्रियन्ते भेमकाञ्चिः १४

© Dharmarth Trust. Digitized By eGangotri

भक्तुवेभ प्रुकावेमभामिट्टेउक्कुयशुन्ते

मुभिड्डे मेभ्भे

भक्लि केविवद सि कमसि॥

कुभ भ्रुमसेकसम॥ उथाभक्कू: पजयहू

उमङीयं यजूसि भिज्ञुये यमतृक्कुम
उक्ँत, मालिक्कोइ, पनाइ्लनाशिविथ
कुभ यंउउ यक्म ॐरंमशि भ्रुमभ्रुभउत्रभ इंयउभामैठु अचकमस मुउ्उंउ
कीउये
सिउिउउ ३ ३७ यजूठ्उपभिसननेमाक्क्रिउ: भामिठ्ठ
इदभा॥ ३७॥

मेनूठे कम्भसेवठमङीयं भामिट्टेव्रु:ठिपी यउ ३७

© Dharmarth Trust. Digitized By eGangotri

ममस्रय फउंमकुंउपमभुंनउंमयउा म

मवनं मनं विवक्तिं कममनमुपि

मुहलिकउत्रेपि

नउलति विउ॥ मुउ नमाम्भिंदे कै बलउयमस्त

भामिदुमृउेपउ नमउडुहनेउद ३३ उ ॥

उम्रीठगावन्नीउम्र मफ विमृयंयेगाम

भेम्रीनम्मुकुनभंवमेहिउ॥ विठगेन

मून विवकयेगे

मी. ०१७ भमभुमभेमृयः ॥ मलनउवम ॥

© Dharmarth Trust. Digitized By eGangotri

[illegible]

भेदकर्त्र्ये॥

विवेकेन

[illegible]

[illegible] ॥

[illegible] १

विवेकिन:

© Dharmarth Trust. Digitized By eGangotri

इत्युक्ते धर्मिणे कैकमधर्मानीषिणः

[illegible]

केवलस्तूनव स्मृतिनिषिद्धः मांसादि॥

मीमांसकः

यत्त्वमनुपः कर्मन हत्वाभिज्ञिभ्यः परे ७

[illegible]

निष्ठयंम [illegible] इगो

[illegible]

मी. ०१० क्रियन्धर्म [illegible] शिविषः अंधकीर्तितः २

© Dharmarth Trust. Digitized By eGangotri

सारगीता

ॐ

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible] ३
[illegible]
गी. भ. टी. ३ [illegible]
[illegible]

© Dharmarth Trust. Digitized By eGangotri

𑆥𑆱𑇀𑆠𑆶𑆩𑆴𑆠𑆱𑇀𑆠𑆶𑆠𑆩𑆱𑆼𑆰𑆁𑆱𑆶𑆮𑆓𑆱𑆶𑆤𑆩𑇀 𑆇
𑆤𑆩𑆤𑆓𑆤𑆴𑆠𑆴𑆩𑆼𑆱𑇀𑆡𑆼𑆟𑆮𑆘𑇀𑆘𑆮𑆱𑆠𑇀𑆠𑆴𑆤𑆳
𑆫𑆩𑆥𑆫𑇀𑆠𑆸𑆁𑆲𑆸𑆢𑆪𑆱𑇀𑆡𑆴𑆠𑆼𑇅𑆱𑆫𑇀𑆮𑆼𑆯𑆳𑆓𑇀𑆤𑆪𑆂𑆤𑆩
𑆕𑆼𑆢𑆼𑆤𑆼𑆤𑆩𑆱𑇀𑆠𑆶𑆫𑇀𑆪𑆱𑆶𑆫𑆠𑆁𑆲𑆸𑆢𑆪𑆱𑇀𑆡𑆴𑆠𑆼𑇅𑆮𑆴𑆠𑇀𑆩
𑆤𑆩𑆵𑆠𑆴𑆁𑆱𑆶𑆮𑆑𑇀𑆫𑆶𑆘𑆼𑆘𑆫𑆤𑆫𑆩𑆫𑇀𑆲𑆴𑆁𑆲𑆸𑆢𑆪
𑆠𑆴𑇅𑆱𑇀𑆠𑆶𑆁𑆱𑆶𑆠𑆴𑆪𑆓𑇀𑆱𑆶𑆠𑆱𑇀𑆠𑆶𑆁𑆥𑆱𑇀𑆠𑆶𑆩𑆴𑆠𑆱𑆼𑆰𑆁𑆮
𑆰𑆟𑆮𑆠𑆴𑆠𑆰𑆠𑆶𑆩𑆤𑆼𑆱𑆶𑆮𑆓𑆩𑆴𑇅𑆠𑆩𑆼𑆢𑆱𑇀𑆠𑆶𑆠
𑆱𑇀𑆠𑆶𑆁𑆥𑆪𑆩𑆤𑇆𑆱𑇀𑆠𑆶𑆠𑆴𑇆𑇓𑇆𑆱𑇀𑆠𑆶𑆩𑆲𑆫𑆴𑆁
𑆩𑆲𑆳𑆩𑆳𑆫𑆩𑆩𑆱𑇀𑆠𑆶𑆪𑆳𑆠𑇀 𑇆𑆡𑆼𑆤𑆼𑆤𑆳𑆠𑆑𑆩

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

© Dharmarth Trust. Digitized By eGangotri

गी. भ.
टी.
७

© Dharmarth Trust. Digitized By eGangotri

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible] ॥ [illegible]

[illegible]

[illegible] ॥ [illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible] [illegible]
[illegible]
[illegible]
[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible] ॥३॥ [illegible]

[illegible] ॥ [illegible]

[illegible] ॥ [illegible]

[illegible] ॥१०

गी० भा०
टी०
७

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

© Dharmarth Trust. Digitized By eGangotri

𑆥𑆜𑆼𑆤𑇀𑆤𑆪𑆁𑆤𑆩𑆱𑇀𑆠𑆶𑆠𑆴𑇁𑆱𑇀𑆩𑆴𑆤𑇀𑆱𑇀𑆠𑆤𑆼𑆩𑆪𑆷𑆒𑆴𑆠𑇀𑆫𑆴𑆠𑆁𑆩𑆠𑆂
𑆫𑆶𑆢𑇀𑆫𑇁𑆨𑆵𑆱𑇀𑆠𑆶𑆫𑇀𑆓𑆶𑆥𑇀𑆫𑆪𑆼𑆮𑆘𑇀𑆚𑆳𑆩 𑆥𑆑𑆸𑆠𑆼𑆤
𑆮𑆥𑆼𑆠𑇆𑇐𑇐𑇆𑇁𑆩𑆼𑆮𑆒𑆑𑆸𑆠𑆩𑇆𑆠𑇀𑆫𑆴𑆯𑆷𑆬𑆩𑆴
𑆠𑆴𑇆𑆠𑇀𑆫𑆴𑆯𑆷𑆬𑆁𑆠𑆁𑆢𑇀𑆮𑆴𑆮𑆴𑆬𑆤𑆵𑆪𑆱𑇀𑆠𑆶𑆲𑆴𑆠𑆢𑆴𑆮𑆁𑆱𑆴
𑆮𑆩𑇆𑇐𑇔𑇆𑆠𑇀𑆫𑆴𑆯𑆷𑆬𑆁𑆥𑆢𑇀𑆩𑆓𑆩𑆼𑇁𑆠𑇀𑆫𑆲𑇀𑆸𑆢𑆪𑆁𑆱𑇀𑆠𑆶
𑆮𑆮𑆢𑇀𑆮𑆴𑆲𑆴𑆠𑆢𑆴𑆮𑆁𑆩𑆴𑆡𑆩𑆳𑆢𑆴𑆮𑆵𑆖𑆁𑆨𑆴𑆮𑆁𑆩
𑆤𑆬𑆱𑇀𑆠𑆶𑆥𑆁𑇁𑆠𑆴𑆮𑆴𑆬𑆤𑆵𑆪𑆱𑆷𑆥𑆼𑆢𑆴𑆤𑆁𑆠𑆂𑇆𑇐𑇔
𑆤𑆵·𑆩 𑆬𑆵· ·· 𑆑𑆴𑆁𑆱𑇆𑆥𑆤𑆱𑇀𑆠𑆶𑆠𑆁𑆩𑆠𑆂𑆱𑇀𑆠𑆶𑆠𑆁𑆧𑆢𑇀𑆣𑆴𑆱𑇀𑆠𑆶𑆠𑆁𑆠𑇀𑆫𑆴𑆫𑆳𑆩
𑆪𑆩𑇆𑆩𑆢𑆱𑇀𑆠𑆶𑆠𑆁𑆠𑇀𑆫𑆴𑆫𑆳𑆩𑆁𑆩𑆩𑆳𑆢𑆴𑆱𑇀𑆠𑆶𑆱𑇀𑆡𑆬𑆱𑇀𑆠𑆶

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

𑆲𑆷𑆁𑆟𑆴𑆠𑆁𑆥𑆷𑆜𑆱𑆑𑆵𑆫𑆢𑇀𑆣𑆴𑆱𑆫𑇀𑆮𑆽𑆂 𑆑𑇀𑆫𑆩𑆼𑆬𑆠𑆱𑆳𑆱

𑆟𑆴𑆪𑆠𑇀𑆫𑆢𑆱𑆁𑆑𑆢𑆴𑆮𑆴𑆪𑆤𑆵𑆪𑆠𑇀𑆮𑆱𑆳𑆟𑆴𑆱𑇀𑆮𑆑𑇀𑆫

𑆤𑇅𑆱𑆽𑆁𑆱𑆳𑆓𑆫𑆑𑇀𑆫𑆤𑇀𑆑𑇀𑆫𑆱𑇀𑆫𑆠𑆱𑆑𑇀𑆫𑆾𑆟𑆮𑆢𑆴𑇆 𑆪𑆮𑆁𑆤𑆵𑆮

𑆑𑇀𑆫𑆠𑆱𑇀𑆫𑆢𑆼𑆤𑆢𑆴𑆱𑇀𑆫𑇅 𑆟𑆴𑆠𑇀𑆫𑆮𑆼𑆱𑆽𑆤𑆱𑆵𑆢𑆤𑆳𑇆 𑆱𑇀𑆫𑆪

𑆱𑆴𑆢𑆴 𑇆 𑆱𑇀𑆫𑆪𑆱𑆱𑇀𑆫𑆬𑆴𑆠𑆢𑆼𑆤𑆼𑆢𑆼𑆤𑆵𑆑𑇀𑆫𑆱𑆷𑆱𑆱

𑆟𑆴𑆤𑇆 𑆮𑆴𑆱𑇀𑆫𑆬𑆁𑆠𑆁𑆢𑆴𑆪𑆤𑆵𑆪𑆠𑇀𑆮𑆱𑆳𑆟𑆴𑆱𑆷𑆪𑆬𑆑

𑆬𑆱𑆳𑇆 𑇐𑇗 𑇆 𑆱𑆼𑆢𑆼𑆱𑇀𑆫𑆪𑆱𑆤𑆳𑆢𑆴𑆥𑇀𑆫𑆓𑇀𑆫𑆑𑇀𑆫𑆱𑆢𑆮𑆱

𑆤𑆮𑆱𑆠𑆱𑇀𑆫𑆬𑆴𑆠𑆟𑆳𑆱𑆤𑆳𑆢𑆴𑆑𑆁𑆠𑇀𑆫𑆮𑆢𑆥𑆴𑆱𑆼𑆢𑆵

𑆤𑆵𑆮𑆼𑆠𑇀𑆫𑆱𑆱𑆱𑆟𑆴𑆤𑆮𑆴𑆱𑇀𑆫𑆬𑆱𑆱𑆟𑆴𑆪𑆼𑆤𑆼𑆤𑆼

© Dharmarth Trust. Digitized By eGangotri

सूक्तं यथा भवति तथा त्वं भासमानं विषणीय
[illegible] सर्वसिद्धियोगयुक्तमिति [illegible] मि
[illegible] ॥ [illegible] ॥ नमस्
मिति ॥ नमस्ते सर्वरूपिणे शिवलिङ्गं ॥
[illegible] वेदवित् ॥ न
विष्णुना [illegible] सर्वगतं [illegible]
[illegible] शिवलिङ्गं [illegible]
[illegible] विष्णुना सेवितं [illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

नी.म
ली.
०३

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

𑇁𑆱𑇀𑆠𑇀𑆫𑆓𑆾𑆥𑆾𑆥𑇀𑆪𑆳𑆩𑆣𑆷𑆠𑇀𑆫𑆴𑆲𑆫𑇀𑆰𑆴𑆁𑆯𑇀𑆫𑆴𑆠𑆲𑆸𑆰𑇀𑆛𑆪𑆾

𑆑𑆸𑆠𑇀𑆪𑆜𑆩𑆩𑆳𑆤𑆼𑆩𑆠𑆴𑆢𑆼𑆲𑆢𑆼𑆱𑆾𑆥𑇀𑆪𑆥𑆴𑆩𑆠𑆴𑆬𑆵

𑆮𑆼𑆬𑆢𑇀𑆫𑆶𑆩𑆳𑆠𑇀𑆫𑆴𑆥𑆢𑆼𑆩𑆤𑇀𑆲𑆷𑆥𑆶𑆰𑆢𑇀𑆓𑆜𑆮𑆼𑆩𑆠𑆴𑇁𑆱𑇀𑆪

𑆪𑆾𑆓𑆥𑆴𑆠𑆯𑇀𑆫𑆴𑆪𑆤𑇀𑆠𑆶𑆩𑆠𑆤𑇀𑆠𑇀𑆫𑆴𑆱𑆴𑆢𑇀𑆣𑆶𑆜𑆬𑆼𑆩𑆳𑆪

𑆤𑆼𑆨𑆪𑆾𑆩𑆤𑆳𑆜𑆮𑆱𑆴𑆠𑆴𑆜𑆮𑆂𑇆𑇐𑇑𑇆𑆥𑆮𑆩𑆢𑇀𑆣

𑇁𑆱𑇀𑆡𑆩𑆾𑆱𑇀𑆠𑆶𑆤𑆵𑆩𑆠𑇀𑆫𑆂𑆩𑆤𑆵𑆱𑆶𑆓𑆥𑆮𑆪𑆾𑆥𑆪

𑆠𑇁𑆱𑆶𑆱𑆶𑆱𑇀𑆡𑆩𑆓𑇆𑆮𑆼𑆢𑆱𑆮𑆴𑆠𑆴𑇆𑆮𑆼𑆢𑆮𑆼𑆪𑆂

𑆱𑆶𑆂𑆨𑆾𑆘𑆼𑆮𑆼𑆢𑆠𑇀𑆫𑆼𑆩𑆱𑇀𑆪𑆠𑆴𑆱𑆴𑆢𑇀𑆣𑆂𑇆𑇁𑆱𑆶𑆱𑇀𑆮𑆠𑆴𑆤𑆵

𑆤𑆱𑆷𑆪𑆂𑆥𑆳𑆂𑆩𑆩𑆤𑆼𑆱𑆷𑆂𑇁𑆠𑆴𑇆𑇐𑇒𑇆𑆮𑆼𑆢𑆱𑆼𑆩𑆮

© Dharmarth Trust. Digitized By eGangotri

𑆮𑇂𑆢𑆱𑆤𑇀𑆠𑇀𑆫𑆳𑆫𑇀𑆡𑆱𑆳𑆫𑆾॥ 𑆮𑇂𑆢𑆱𑇀𑆪𑆪𑆂 𑆱𑆶𑆧𑆤𑇀𑆣𑆥𑆫𑆴𑆘𑇀𑆚𑆳

𑆪𑆠𑆴𑆯𑆵𑆪𑆱𑆳𑆤𑇀𑆠𑆂॥ 𑆮𑇂𑆢𑆠𑇀𑆫𑇂𑆱𑆩𑆮𑆱𑆤𑇀𑆠𑇀𑆫𑆳𑆫𑇀𑆡𑆱𑆁𑆠𑇀𑆫𑇂𑆯𑆁

𑆱𑆢𑇀𑆮𑆸𑆠𑇀𑆠𑆱𑆤𑇀𑆣𑆥𑆫𑆴𑆘𑇀𑆚𑆳𑆪𑆡𑇀𑆫𑆴𑆯𑇀𑆖𑆴𑆠𑆂 𑆱𑆁 𑆱𑆶𑆮𑆴𑆠𑆂

𑆩𑆑𑆳𑆫𑆳𑆤𑇀𑆠𑆮𑇂𑆢𑆳𑆤𑇀𑆠𑆳𑆫𑇀𑆡𑆪𑆮𑇂𑆢𑆩𑆣𑆷𑆩𑆤𑆴𑆯𑇀𑆖𑆴𑆠𑆪𑆂

𑆱𑆳𑆂 𑆱𑆤𑇀𑆮𑆤𑇀𑆢𑆑𑆶𑆠𑆱𑆪𑆱𑆠𑆴𑆬𑇀𑆬𑆵𑆤𑆱𑆪𑆥𑆳𑆮𑆑𑆶

𑆱𑆁𑆬𑇀𑆬𑆵𑆤𑆱𑆪𑆂 𑆥𑆳𑆂 𑆥𑆫𑆴𑆮𑆤𑇀𑆠𑆶𑆫𑆱𑆪𑆮𑇂𑆚𑆑𑆂

𑆫𑆥𑆬𑇀𑆬𑆑𑆁𑆱𑇂𑆯𑇀𑆱𑆮𑆱𑆤𑇀𑆠𑆑𑇀𑆫𑆴𑆪𑆑𑆳𑆫𑆮𑆤𑆱

नी.स. 𑆮𑇂𑆚𑆑𑆂 𑆱𑆮𑆤𑆴𑆪𑆠𑆱𑆮𑆠𑆶𑆢𑆱𑆵𑆪𑆱𑆢𑇂𑆯𑆳𑆠

टी. 𑆠𑆴𑆫𑆱𑆴𑆢𑇀𑆢𑆂 𑆱𑆳𑆫𑆤𑇀𑆢𑆶𑆢𑇀𑆢𑆵𑆤𑆱𑆶𑆠𑆠𑆂॥

०३

०५

𑆯𑆳𑆱𑆷𑆢𑆷𑆥𑆴𑆫𑆳𑆠𑆜𑆮𑆢𑆸𑆮𑆁𑆪𑆮𑆁𑆯𑆳𑆱𑆷𑆜

𑆤𑆪𑆪𑆱𑆂𑆫𑆻𑆠𑆶𑆬𑆶𑆠𑆻𑆩𑆢𑆱𑆴𑆤𑆤𑆠𑆑𑆶𑆠𑆩𑆤

𑆑𑆠𑆲𑆢𑆲𑆤𑆳 𑇆 𑆤𑆮𑆤𑆵𑆠𑆴 𑇆 𑆤𑆮𑆤𑆵𑆜𑆮𑆼

𑆢𑆮𑆲𑆮𑆢𑆶𑆫𑆁𑆤𑆓𑆷𑆠𑆴 𑇆 𑆢𑆠𑆵𑆬𑆼𑆜𑆩𑆴𑆢𑆶

𑆫𑆤𑆮𑆲𑆴𑆁𑆮𑆼𑆢𑆪𑆼𑆕𑆤𑆩 𑇆𑇑𑇑𑇆 𑆪𑆮𑆲𑆮

𑆢𑆶𑆠𑆶𑆁𑆥𑆫𑆁𑆤𑆱𑆵𑆥𑆫𑆵𑆱𑆁𑆤𑆓𑆷𑆠𑆴𑆤𑆩𑆶𑆑𑆵𑆴

𑆢𑆮𑆢𑆶𑆠𑆁𑆤𑆮𑆤𑆵𑆤𑆱𑆵𑆢𑆳𑆩𑆤𑆤𑆵𑆜𑆮𑆼

𑆑𑆶𑆪𑆢𑆶𑆫𑆴𑆢𑆶𑆫𑆼𑆤𑆱𑆵𑆢𑆵𑆫𑆢𑆠𑆵𑆬𑆼𑆩𑆢𑆴𑆤𑆮𑆤

𑆱𑆵𑆢𑆳𑆩𑆤𑆼𑆤𑆲𑆴𑆁𑆢𑆪𑆼𑆕𑆤𑆁𑆑𑆴𑆩𑆥𑆴𑆤𑆠𑆵𑆢𑆱 :

© Dharmarth Trust. Digitized By eGangotri

एकस्मि तद्धर्मि केष्ठ डेमामूद्वि तौः
किंपुषे नमिडितवः ॥ ०७ ॥ एडेवतन्न
तो ऽमत्स्नुतमिहं ॥ तत्रमिडि ॥ तत्रम
हम्मणवीष्ठनविष्ठनङ्द्रूः ॥ पन्नालमि
वणज्ञीहत्स्नुनमेषंडः ॥ ७० ॥ मणवी
तत्रत्वङ्किम नृत्नमहम्नवेदत्मस्वं नहण्ठ
तेमम तृष्ठने विष्ठने विमेष त्रठवम ङ्द्रूः

गी. अ. मत्रृत्रेमम्नूलङहेपदष्ठसतुः । णत्रजी

टी. णत्रमगिङ्हं ममयङ्त्रपणत्रवीकम

०८

© Dharmarth Trust. Digitized By eGangotri

नत्रांयघ्राभललालोकुल्मिसगद्दूंयघाह
९डिडस्त्रुम्रिडेत्रः॥ ७० ॥ उत्तेत्रेदघुत्रुत्र
भग ॥ उल्लुडि ॥ उल्लुनम्रुंयघालिकेडूह
भलिकूडूंडूलेडा ॥ ल्लुनेनल्लुनभलिकेत्रुंय
स्त्रद्दहिरेडा ॥ ७० ॥ कस्त्रिल्लिकेडूकागश्चि
डडूहगत्रनतीभवबिल्कुनम्रुउल्लुकनश्चि
छवडिमस्त्रदूहभलिकेडगनत्रांडमल्लं
यघहूले डघस्त्रुनेनल्लुनभगनेनल्लुयंकूत्र
लिकेत्रुमेमीनहमस्त्रुल्लुनंल्लुनभगनंमश्चि

© Dharmarth Trust. Digitized By eGangotri

𑆝𑆼𑆮𑆴𑆢𑇀𑆣𑆷𑆂𑇆𑇑𑇐𑇆𑆌𑆠𑆼𑆯𑆳𑆥𑆾𑆏𑆾𑆘𑇀𑆛𑆼𑆠𑆼𑆤𑆯𑇀𑆮𑆣𑇀𑆤𑆼
𑆤𑆳𑆕𑆏𑆁𑆡𑆳𑆁𑆤𑆼𑆁𑆥𑆳𑆯𑆴𑆢𑆴𑆢𑆴𑆧𑆴𑆠𑆼𑆯𑆁𑆡𑆷𑆮𑆶𑆠𑆼𑆠𑇀𑆩𑆼𑆢
𑆯𑆷𑆤𑇆𑆨𑆡𑆾𑆑𑇀𑆠𑆴𑇆𑆨𑆡𑆳𑆥𑆷𑆠𑆼𑆤𑆢𑆶𑆂𑆐𑆶𑆣𑆨𑆧𑆳𑆁𑆏𑆴𑆁
𑆯𑇀𑆮𑆣𑇀𑆤𑆼𑆤𑆳𑆧𑆳𑇆𑆃𑆬𑆁𑆯𑆳𑆤𑆧𑆁𑆏𑆳𑆁𑆠𑆼𑆬𑆳𑆯𑆼𑆯𑇀𑆩𑆴𑆫
𑆣𑆼𑆤𑆳𑆧𑇆𑇑𑇑𑇆𑆨𑆡𑆳𑆥𑆷𑆠𑆼𑆤𑆧𑆳𑆤𑆯𑆧𑆥𑆼𑆤𑆶
𑆛𑆼𑆤𑆢𑆶𑆂𑆐𑆶𑆧𑆞𑆶𑆂𑆐𑆶𑆣𑆨𑆧𑆳𑆤𑆵𑆫𑆯𑇀𑆮𑆣𑇀𑆤𑆼𑆤𑆁
𑆤𑆴𑆩𑆃𑆬𑆁𑆣𑆳𑆧𑆁𑆛𑆼𑆘𑆠𑆣𑆳𑆧𑆳𑆢𑆤𑆧𑆣𑆾𑆩𑆵
नी॰ म॰ 𑆢𑆢𑆬𑆼𑆯𑆼𑆬𑆤𑆞𑆧𑆳𑆯𑆷𑆢𑆨𑆤𑆼𑆂𑆏𑆴𑆁𑆯𑇀𑆮𑆣𑇀𑆤𑆼𑆤𑆁𑆏𑆴
टी॰
०१ 𑆧𑆵𑆠𑆷𑆂𑇆𑆖𑆬𑆼𑆬𑆼𑆤𑆧𑆳𑆡𑆤𑆞𑆣𑆾𑆢𑆳𑆫𑆴𑆛

© Dharmarth Trust. Digitized By eGangotri

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible] ॥ १३ ॥ [illegible]

[illegible] ॥ [illegible] ॥ [illegible]

[illegible] ॥ [illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

हमक्षत्र्युपमवरयोतःमद्रोत्रप्रवित्ताप
कालेऽविजुद्धवज्जयास्त्रिदज्यकदत्रेनधि
वद्धेऽभावदयाभक्तंतंपञ्चेतवहेऽदयः ३८
यवदयमेवातदवपदतंस्वयंरक्षमहत्
कारुभाव ॥ इदमिति ॥ इदंसंपाभक्तं
पंचाक्षेद्वद्वहनहणीः ॥ विभ्रमासिसितिंपे
वंपञ्चेपदतंविधन्नम ॥३१॥ देवज्ञवि
गी. भ. भ्रमासिसितिंविनाऽभ्रमास्तिसिसावहेऽ
टी. मानमदतंविधन्लंतडिस्तुतंदेवंस्वयंरक्ष
०१

𑆱𑆨𑆳𑆠𑇀𑆫𑆁𑆥𑆳𑆠𑇀𑆫𑆩𑆢𑇀𑆨𑇀𑆪𑆁𑆠𑇀𑆫𑆁𑆔𑆳𑆮𑆢𑇀𑆨𑇀𑆫𑆱𑇀𑆩𑆼𑆱𑆥𑆿𑆫𑆑𑆵𑆠𑆢
𑆝𑆮𑆝𑆢𑆱𑆁𑆥𑆳𑆠𑇀𑆫𑆩𑆢𑇀𑆨𑇀𑆫𑆢𑇀𑆣𑇀𑆪𑆁𑆰𑇀𑆢𑆴𑆣𑆸𑆣𑇀𑆪𑆁𑆯𑇀𑆫𑆠
𑆠𑇀𑆫𑆶𑆟𑆵𑆫𑆼𑆑𑆩𑆴𑆝𑆂𑆩𑆢𑇀𑆨𑇀𑆮𑆼𑆱𑆰𑆢𑆟𑇀𑆟𑆳𑆁𑆠𑆸𑆢𑆥𑆴
𑆝𑆂𑆂 𑇆𑇓𑇑𑇆 𑆠𑆮𑆠𑇀𑆫𑆑𑆳𑆩𑆼𑆮𑆰𑆢𑆴𑆣𑆸𑆣𑇀𑆪𑆫
𑆑𑆛𑆠𑆲𑆬𑆴𑆁𑆠𑆮𑆴𑆩𑆢𑆪𑆝𑆴 𑇆 𑆠𑆢𑇀𑆨𑇀𑆶𑆝𑆝𑆴 𑇆 𑆠𑆢𑇀𑆨𑇀𑆼
𑆥𑆴𑆠𑆝𑆳𑆨𑇀𑆶𑆂𑆥𑆴𑆝𑆨𑇀𑆶𑆂𑆥𑆴𑆝𑆮𑆬𑆴𑆝𑆂 𑇆 𑆝𑆴𑆩
𑆬𑆂𑆩𑆮𑆝𑆼𑆢𑆼𑆑𑆵𑆩𑆮𑆲𑆳𑆥𑆵𑆠𑆴𑆓𑆞𑇀𑆲𑆠𑆂 𑇆𑇓𑇆
𑆢𑆼𑆑𑆵𑆬𑆵𑆮𑆂𑆩𑆮𑆝𑆩𑆮𑆥𑆴𑆢𑇀𑆨𑇀𑆬𑆼𑆝𑆳𑆢𑇀𑆨𑇀𑆥𑆞

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible] शरीरसंबंध [illegible]

[illegible] शरीरसंबंध [illegible]

[illegible]

[illegible]

[illegible] ॥ ७ ॥ किंच

गी. भा. [illegible]

टी. [illegible] ॥ कथमुच्यते ॥ कथम् [illegible]

१३

© Dharmarth Trust. Digitized By eGangotri

कश्यपः कश्यपमुपित्रलयाइ ॥ कश्यपमुपित
श्यान्तः कश्यपमुपित्रवपुत ॥ ३७ ॥ मरवशे
दीकश्यपमुपिमगीशपुमवत्रपित्रकश्यपमु
वमुतसुगीगविमित्रवशुगकिडः कश्यपमुपि९
मदिवमुगीगमुपित्रलयाडमगीगविमित्रव
९ मादिडडउड्डः कश्यपमुपित्रैमावीड
डमगीदपित्रश्यान्तैतैगकिडः कश्यपमुपि
वकुतेउक्तु डमेश्यमुपित्रवपुतेवहुंत्रमैशी
उड्डः । किंत्रकश्यपमुडडि ॥ कश्यपमुपित्रलित्रः

© Dharmarth Trust. Digitized By eGangotri

स्तुक्रयस्मै पितृवर्णद्धे ॥७५॥ कव्यस्मै पितृभ्यः :
पितृभ्यः स्वधास्मै पितृतल्पेभ्यः स्तृक्यस्मै पितृ
नित्यस्तुगतिः स्वधानमः । स्वधा कव्यस्मै पितृभ्यः
ब्रह्मणे तस्मै पितृवन्द्धे न्रिप्रिय स्वधानमः ॥
नेत्रं स्मिन्निष्टु वद्विकाम्सुद्वदं गत्विद्धं ॥ य
मधुवेनद्धं मेतद्धं मडि स्मृगवन्ध्येवट
द्रगवद्धविमन्त्रीयस्वधान ॥ तिलमद्वेशी
गी.म. तिलमद्वेयघद्वेलंदीमद्वेयघपतिम
सी. तिलमद्वेयघद्वेलंदीमद्वेयघमात्म
७७ भुवमद्वेयघमायुः तत्त्वमद्वेयघमयः ॥

© Dharmarth Trust. Digitized By eGangotri

𑆑𑆫𑇀𑆥𑆷𑆫𑆯𑆴𑆮𑆫𑆷𑆥𑆑𑆱𑆼𑆠 𑆩𑆶𑆑𑆱𑆼𑆮𑆪𑆶𑆮𑆱𑇀𑆮𑆴𑆓𑆩𑆴𑆠𑆴 𑇅 𑇑𑇗

𑆠𑆴𑆬𑇀𑆬𑆩𑆥𑇀𑆫𑆼𑆠𑆼𑆬𑇀𑆬𑆱𑇀𑆑𑆶𑆱𑆑𑆠𑆴𑆬𑇀𑆬𑆼𑆥𑆶𑆪𑆡𑆼𑆠𑆼𑆬𑇀𑆬𑆁𑆪𑆠𑇀𑆫

𑆱𑆴𑆤𑆴𑆠𑇀𑆫𑆴𑆱𑇀𑆪𑆵𑆠𑆤𑆢𑇀𑆫𑆶𑆡𑆑𑇀𑆫𑆷𑆑𑆁𑆟𑆩𑆠𑆑𑇀𑆱𑆵𑆓𑆩𑆥𑇀𑆫𑆼

𑆑𑆵𑆓𑆢𑆶𑆥𑆼𑆤𑆼𑆢𑆼𑆤𑆼𑆩𑆪𑆪𑆑𑇀𑆫𑆶𑆓𑆱𑆮𑆴𑆥𑆴𑆓𑆶𑆩𑆩

𑆡𑆼𑆥𑆤𑆠𑆤𑆮𑆤𑆵𑆠𑆠𑇀𑆫𑆴𑆱𑆁𑆪𑆼𑆤𑆢𑇀𑆫𑆶𑆡𑆥𑆠𑆁𑆑𑇀𑆱𑆵

𑆪𑆠𑇆𑆥𑆶𑆑𑇀𑆱𑆩𑆥𑇀𑆫𑆼𑆱𑆪𑆡𑆓𑆑𑆷𑆂𑆮𑆑𑇀𑆱𑆴𑆩𑆠𑇀𑆫𑆶𑆪𑆡𑆢𑇀𑆫𑆼𑆥

𑆡𑆑𑇀𑆫𑆷𑆓𑆵𑆪𑆠𑆼𑇆𑆟𑆬𑆩𑆥𑇀𑆫𑆼𑆱𑆪𑆡𑆢𑇀𑆫𑆶𑆓𑆥𑇀𑆫𑆷𑆱𑆴𑆠𑆼𑆪𑆁

𑆱𑆢𑆓𑆼𑆤𑆓𑆩𑆂𑆥𑆡𑆑𑇀𑆫𑆴𑆪𑆠𑆼𑆑𑆫𑇀𑆥𑆷𑆫𑆯𑆴𑆮𑆱𑆓𑆢𑇀𑆫𑆷

𑆱𑆴𑆱𑇀𑆫𑆴𑆠𑆠𑇀𑆫𑆴𑆱𑇀𑆩𑆡𑆤𑆢𑇀𑆫𑆶𑆡𑆑𑆫𑇀𑆥𑆷𑆟𑆁𑆮𑆴𑆤𑆪

प्रयंप्रक्रमस्य परमते । शुक्लसेमपषादयुः
सवाः सत्रातिरक्ष; रक्तमक्षश्रमयास्मिंस
सेशुसशुद्धेयंमदृशेनानक्षक्षकरपप्रयंरक्
सः सत्त्वसतेरुदन्तः ॥२२॥ रदेवरहपूर्तिके
सर्वस्वश्रुप्रपपरपति । रक्षति ॥ रक्षसर्व
गतिस्तेकीसिदसहृदयस्थितः ॥ सर्वभूतेषि
तंस्तेवसर्वसहृदयस्थितः ॥ २० ॥ प्रवेत्तर
गी. भ. क्रोधोत्तरैल्लसिवस्रवाराः सर्वदापीरतेकीसी
टी. वेदेदसहृत्तानठसठित्रतिद्रूरस्तिसहृवि
७.

[illegible]

© Dharmarth Trust. Digitized By eGangotri

नमः [illegible] नमः [illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible] ॥ ३० ॥ [illegible]

[illegible] ॥ [illegible] ॥ [illegible]

१० [illegible] ॥ [illegible]

© Dharmarth Trust. Digitized By eGangotri

𑆱𑆩𑆳𑆥𑆴𑆱𑆶𑆥𑆹𑆱𑆷𑆢𑆼 𑇆 𑇓𑇗 𑇆 𑆩𑆤𑆱𑇀𑆠𑆶𑆑𑆩𑆮

𑆠𑇀𑆫𑆴𑆱𑆶𑆬𑆁𑆤𑆶𑆣𑆢𑆓𑆩𑆤𑆂𑆩𑆑𑆬𑇀𑆥𑆳𑆢𑆴𑆑𑆬𑇀𑆥

𑆣𑆑𑆁𑆠𑆴𑆫𑆩𑆢𑆁𑆠𑇀𑆫𑆴𑆮𑆴𑆩𑆪𑆁𑆤𑆶𑆣𑆠𑇀𑆫𑆴𑆱𑆶𑆬𑆁𑆠𑇀𑆫𑆴

𑆱𑇀𑆠𑇀𑆫𑆴𑆮𑆩𑆵𑆱𑆶𑆁𑆮𑆾𑆢𑆴𑆥𑆤𑆵𑆪𑆣𑆥𑆮𑆱𑆩𑆳𑆥𑆴

𑆱𑆶𑆥𑆹𑆱𑆷𑆢𑆼 𑇆 𑆢𑇀𑆮𑆴𑆱𑆩𑆣𑆶𑆤𑆩𑆼𑆮𑆱𑆩𑆳𑆥𑆴𑆱𑆶𑆥𑇀𑆫

𑆥𑆴𑆬𑆩𑆢 ~ 𑆩𑆴𑆢𑆶𑆂 𑇆 𑇓𑇗 𑇆 𑆥𑆮𑆩𑆑𑆶𑆥

𑆥𑆴𑆬𑆩𑆢 ~ 𑆩𑆑𑇀𑆱𑆤𑆢𑆾𑆥𑆳𑆪𑆩𑆳𑆢 𑇆 𑆮𑆾𑆤

𑆱𑆶𑆬𑆩𑆢 ~ 𑆩𑆑𑇀𑆱𑆤𑆢𑆾𑆥𑆳𑆪𑆩𑆳𑆢𑆂

𑆩𑆠𑆼𑆢𑆴 𑇆 𑆮𑆾𑆤𑆩𑆠𑆫𑆩𑆁𑆥𑆵𑆢𑆮𑆪𑆶𑆠𑆩𑆢𑆂

𑆩𑆢𑆱𑆶𑆥𑆵 𑇆 𑆪𑆩𑆩𑆣𑆶𑆩𑆢𑆴𑆁𑆩𑆩𑆳𑆥𑆴𑆢𑆶

© Dharmarth Trust. Digitized By eGangotri

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
𑆓𑆵𑇆 𑆃𑇆 [illegible]
𑆛𑆵𑇆 [illegible]
𑇑𑇑 [illegible]

© Dharmarth Trust. Digitized By eGangotri

ग्रस्रुतमणः स्रुतं मष्टस्रुतं यमज्ञकर्म्मा म
चस्रुतं मस्रज्ञेडिभमणिम्रुम्लकन्ति म ॥ ३८
ग्रस्रुतमस्रुदेसेपगिस्त्रुमगदिनमणः स्रुतम
णिदेसैंपगिस्त्रुमगदिनं, मष्टस्रुतं मष्टदेमपगि
स्रुमगदिनं, मवस्रुतं देमकर्ल्लाध्रिपगिस्त्रुमग
दिनं यमज्ञकं पस्त्रुतं मस्रज्ञेडिठवनमम
णिम्रुम्लकन्ति मिहस्रः ॥ ३८ ॥ पस्रुमस्त्र
दष्टुचिठिनिमिणडीस्रुमग ॥ स्रुदेडि ॥ ॥
स्रुतठविडठवज्ञमवपपेः प्रमष्टडे ॥ स्रुत

© Dharmarth Trust. Digitized By eGangotri

𑆩𑆴𑆡𑇀𑆪𑆳𑆥𑆫𑆴𑆱𑇀𑆛𑆶𑆪𑆳𑆓𑇀𑆫𑆳𑆲𑆴𑆠𑆩𑆴𑆠𑆴𑆤𑆮𑆴𑆢𑆼𑆮𑆳𑆩𑆴𑆠𑆂𑆤
𑆢𑆼𑆤𑆴𑆪𑆼𑆪𑆱𑇀𑆮𑆣𑇀𑆫𑆳𑆱𑆼𑆮𑆱𑇀𑆮𑆩𑆱𑇀𑆮𑆫𑆤𑆮𑆴𑆠𑆤𑆮
𑆱𑇀𑆮𑆪𑆼𑆓𑆵𑆥𑆶𑆱𑇀𑆥𑆼𑆂𑆮𑆴𑆤𑆴𑆮𑆴𑆥𑆟𑆥𑇀𑆪𑆶𑆠𑇀𑆠𑆼𑆂𑆱𑇀𑆮
𑆱𑆷𑆠𑆼𑇅𑆨𑆑𑇀𑆠𑆼𑆤𑆮𑆵𑆢𑆠𑆼𑆂𑇆𑇓𑇑𑇆𑆪𑆢𑇀𑆮𑆁𑆤𑆳𑆮𑆢𑆶𑆥
𑆱𑆴𑆢𑇀𑆣𑆶𑆩𑆩𑆥𑆼𑆮𑆴𑆤𑆩𑆩𑆩𑆷𑆮𑆁𑆱𑆳𑆲𑇀𑆫𑆤𑇀𑆠𑆢𑇆
𑆮𑆢𑆷𑆠𑆴𑇆𑆮𑆢𑇀𑆪𑆤𑆳𑆩𑆪𑇆𑆮𑆢𑇀𑆪𑆼𑆤𑆮
𑆤𑆤𑆩𑆴𑆢𑆱𑆷𑆩𑆼𑆠𑆑𑇀𑆫𑆴𑆤𑆱𑆴𑆠𑆴𑇆𑆮𑆢𑆤𑆩𑆱𑆁
𑆓𑆵.𑆨𑆳. 𑆮𑆢𑆑𑆮𑆁𑆱𑆪𑆠𑇀𑆫𑆴𑆪𑆾𑆓𑆴𑆤𑆂𑇆𑇓𑇒𑇆𑆮𑆢𑆼
𑆛𑆵.
𑇙𑇓 𑆬𑇀𑆬𑆤𑆾𑆢𑆮𑆪𑆶𑆠𑆴𑆤𑆮𑆤𑆱𑆷𑆤𑆁𑆤𑆱𑆴𑆤𑆠𑆢

© Dharmarth Trust. Digitized By eGangotri

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

नी. म. [illegible]

टी. [illegible]

१८ ॥

[illegible] ॥
[illegible] योगिनः ॥ १३ ॥
[illegible]
[illegible]
[illegible]
[illegible] ॥ ३५ ॥ [illegible]
[illegible]
[illegible]
[illegible] ॥ [illegible] ॥ [illegible]

© Dharmarth Trust. Digitized By eGangotri

गद्वेत्रवास ॥ हृदयं निर्मलं दृष्ट्वा मित्रपि
दृष्ट्वा नमयम्भ ॥ श्रद्धेवं मिसंभवेङ्डिप
सूर्द्धं भगवति ॥ २७ ॥ हृदयं मित्रं निर्म
लं दृष्ट्वा निरीतिरागा पिरिषगळिइं दृष्ट्वा सग
मवं मित्रपि दृष्ट्वा खोगं सूर्द्ध पागमश्रापीमप
रभा नदृष्टः सत्रेकपद्य नमिसंभवेत्ग
दृष्टं मनमेव नमत्रेटिरिज्ञमनिशिप
गी. भ. सूर्द्धा, श्रपीक्षा वरुवंस श्रुयापिटतुः ॥ ३७
टी.
९१ सल्लनउवास ॥ सहज्ञालिभमम्हलिमवेद्रि

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

मच्छ्वस्यस्मच्छ्र स्तोत्रस्तुतिः ॥ श्रीरामनामं
तिर्थं धर्मनामं भवः ॥ ६६ ॥ वेदविलयं ति
स्त्रिभिः पापसंभवम् ॥ ६७ ॥ श्रीरामस्मरणस्य
पापभ्रमणस्य वर्णस्तोत्रस्तुतिः सर्वः स्य
नमस्ते तिरामनाम्यलक्ष्मीनारायणं, देवदेव
रूपकल्याणं नमस्ते रघवः तिरस्कृतं, श्रीराम
कल्याणं रामचन्द्रं, दितिदितिः, मनस्विनि
रामचन्द्रं नमस्ते रघुवरं स्वभिः, स्वधर्म
नमितं देवः कल्याणः भगवान् रामचन्द्रः ॥

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible] [illegible]

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

नी.ली.
म.
३५

© Dharmarth Trust. Digitized By eGangotri

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

© Dharmarth Trust. Digitized By eGangotri

सकृत् नियम्य विहाय स्वी नियां नियं सन्त्रिया ।
नि सकृत् स्वी नियम स्वी नियम ज्ञानकर्म कृ
नियम्य त्तः पात्रे देव ऽः पात्रे क्रिया नि
नियोगिम्य ऽपयः । ऽन्ते । मन्मा त्रागि
ध्येन्द्रिये व म व देव मतिमन्तः मन
कृत्य विधय युक्त य व कृत न विनिष्ठ मयो
युक्त त्वं न च ये ऽ । ऽ व हि व न ली व
मतिन लिङ्ग मगोऽ मन त्कृति । ये
ये त्त त्रं च युक्ति त्रिकं स सम्यग्

गी. अ.
टी.
१७

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]
[illegible]
[illegible]
[illegible] ॥५२॥ [illegible]
[illegible]
[illegible] ॥ [illegible] ॥ [illegible] ॥
[illegible] ॥ [illegible]
गी॰भ॰ [illegible] ॥५३॥
टी॰
३॰ [illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible] । [illegible] ॥ [illegible]
[illegible] ॥
[illegible] ॥ ५७
[illegible]
[illegible]
[illegible] ।
नी. म. [illegible]
नी. [illegible]
३० [illegible] ॥ ७॰ ॥ [illegible]

© Dharmarth Trust. Digitized By eGangotri

ऽश्वेनमश्वंनमहृभिर्ण्ड्येऽनणगद

ना॥ श्रीगणेशायनमः॥ ओंकारेहृदयाय

स्वाहाकारमहापिंडमपड॥ ओंकारमभूत

मश्चिनिः मश्वं वसिमिशृऽ॥१०॥ ओंकारमेम

नकरमः स्वकरमः पशिश्चित्रकरमछ

यमष्टकमेनरकरमऽसद्दक्रुतेनमश्चित्र

हृभिर्तंहृदयं ऽनपरनकऽयाऽमशिशि

त्रेनववीदक्रः॥ऽक्रुपरनत्रमसरुप्र

शिशित्रवमप्तिरुऽस्त्रफ॥ ओंकारमस्त्रिरु॥

© Dharmarth Trust. Digitized By eGangotri

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]
[illegible]
[illegible] ॥१०॥
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible] ॥१०॥ [illegible]

[illegible]

[illegible] ॥ [illegible] ॥ [illegible]

[illegible] ॥ [illegible]

[illegible] ॥ [illegible]

[illegible] ॥११॥

गी. भा. टी. [illegible]

३३ [illegible]

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

ठलानः ॥ ॐ देवि ॥ सलज्जम ॥ ॐ दम

वाङ्मयं ज्ञभवकृतशक्ति मिडमा ॥ ॐ ह्रीं

ॐ श्रीं ओं नकथं मिकृत्रियोगनः ॥ २३ ॥

वंधसुगावं पुनःवलज्जे यं धनप्रेक्षाली

गावनौ ॥ ॐ ह्रीं यथिमेनकथं मिकृत्रिके

नेयपथनमकजगीरुः ॥ ॐ ह्रीं यां ॐ डि

स्त्रीणावनवम ॥ ॐ ह्रीं ॐ श्रीं ओं नदे

गी.भ. धस्त्रिभनवः ॥ देहेनक्षुडेविक्रिडक्रि

टी. नमेकडिङडि ॥ भनवमवप्रू ॐ ह्रीं यां ॐ

३८

© Dharmarth Trust. Digitized By eGangotri

𑆠𑆴𑆓𑆾𑆁𑆤𑆘𑆴𑆲𑇀𑆮𑆪𑆴𑆮𑆪𑆩𑆤𑆤𑆢𑆼𑆃𑆤𑆳𑆮𑆩𑆱𑇀𑆠𑆶𑆠𑆴

𑆱𑇀𑆛𑆶𑆱𑇀𑆠𑆶𑆠𑆴, 𑆇𑆓𑇀𑆫𑆼𑆣𑆤𑆳𑆥𑆴𑆩𑆴𑆘𑆴𑆲𑇀𑆮𑆪𑆤𑆳𑆁𑆩𑆱𑇀𑆛𑆼𑆤

𑆩𑆪𑆝𑆴𑆜𑆮𑆂 𑇆 𑆝𑆩𑆜𑆼𑆮𑆱𑇀𑆛𑆤𑆼𑆩𑆮𑆤𑆱𑇀𑆫𑆵𑆁𑆲𑆤

𑆱𑆼𑆤𑆝𑆴, 𑆤𑆱𑇀𑆮𑆶𑆢𑆼𑆜𑆩𑆳𑆝𑆴𑆮𑆘𑆴𑆲𑇀𑆮𑆂𑆇𑆱𑇀𑆠𑆶𑆝𑆶𑆱𑇀𑆛𑆼𑆁

𑆇𑆝𑆂𑆮𑆘𑆴𑆲𑇀𑆮𑆩𑆼𑆝𑆶𑆱𑇀𑆛𑆤𑆜𑆮𑆩𑆱𑇀𑆛𑆝𑆱𑇀𑆮𑆥𑆾𑆑𑆳

𑆱𑇀𑆛𑆴𑆝𑆇𑆝𑆂 𑆇𑆓𑇀𑆫𑆼𑆢𑆼𑆘𑆴𑆲𑇀𑆮𑆪𑆱𑆴𑆜𑆢𑆱𑇀𑆛𑆤

𑆤𑆱𑇀𑆮𑆮𑆇𑆱𑆴𑆑𑆼𑆮𑆝𑆶𑆱𑇀𑆛𑆤𑆑𑆳𑆁𑆱𑆴𑆝𑆴𑆜𑆮𑆂 𑇆 𑇑𑇘 𑇆

𑆝𑆢𑆩𑆑𑆳𑆁𑆪𑆮𑆢𑇀𑆢𑆠𑆩𑆠𑆱𑇀𑆮𑆶𑆪𑆱𑆴𑆢𑆩𑆱𑇀𑆛𑆮

𑆜𑆴𑆩𑆤 𑇆 𑆝𑆮𑆱𑆴𑆝𑆴 𑇆 𑆝𑆮𑆩𑆼𑆮𑆤𑆴𑆓𑆾𑆁𑆂𑆱𑇀𑆛𑆶𑆮

© Dharmarth Trust. Digitized By eGangotri

[illegible] ॥ [illegible]

[illegible] ॥११॥ [illegible]

[illegible]

[illegible] ॥

[illegible]

[illegible]

[illegible] ॥११॥ [illegible]

गी॰ भा॰ टी॰ [illegible]

[illegible] ॥ [illegible]

३१

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

अहृवडङ्कूभक्तिम्यदत्तुंमणवेनयङ्गः क
ड्ढः लघुमडङ्कुवरोणदिणिनिधणडीडङ्क्त
नकेपिकडढःयद्गुत्स्तेणिभ्रयदन्तड॥ श
टत्तडि॥ श्वटत्तभालिनेमेत्तेमेत्तीमटत्तवि
मलः॥ उघोत्तंप्रकुकभ्रमतंविणीय
ते॥१२॥ मेतः पाङ्गिडकेटत्तभालिनेम
स्त्रक्षेडिकङ्गुडिकवः, मेतीमेत्कवविन
गी॰भ॰ भ्रुतकृः भवटत्तविमलः श्वतकृभेपवि
टी॰ कभुभभ्रुङ्गिंभ्रुगलिडङ्केवभूयोमेतङ्क
३

[illegible]
[illegible]
[illegible]
[illegible]
[illegible] ॥९
[illegible]
[illegible] ॥१० ॥ ॐ श्रीग[illegible]
[illegible] नमः ॥ ॐ [illegible]
[illegible] ॥ [illegible]

© Dharmarth Trust. Digitized By eGangotri

गी॰ भा॰ टी॰ ३१

श्रुतिभिद्यस्कृति ॥ स्कृति ॥ स्वस्त्वनतव
म ॥ स्कृर् भवान्द्रोणः भवत्स्वामिसुखा
स्वर्णमदेदितिज्ञिमेयु स्वम ॐ द्वहिंसदेसि
हेठावत्र रु विभ्रकृतमेस्तं भवान्द्रोणः
पशिभुलं भवत्स्वं भवभाविकृतमेस्तं भा
मश्रुं भवतिपरमकमिदिस्त द, दस्तु मपीद
प्रिकस्वे दिविभिरू स्वर्णदेदि, भूदिविभक्त
पीवेदेदितिज्ञिमेस्वं वत्ते, दडपितेति
भूमस्तिं किमुयपरमकमित्र: ॥०॥ सर्वं

© Dharmarth Trust. Digitized By eGangotri

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

© Dharmarth Trust. Digitized By eGangotri

गी. भ.
टी.
७५

© Dharmarth Trust. Digitized By eGangotri

[illegible]
[illegible]
[illegible]
[illegible]
[illegible] ||3|| [illegible]
[illegible]
[illegible] || [illegible] || [illegible]
[illegible] || [illegible]
[illegible] || [illegible] || [illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible] ॥८॥ [illegible]

[illegible] ॥ [illegible]

[illegible] ॥ [illegible]

[illegible] ॥ [illegible]

[illegible] ॥५॥ [illegible]

गी. भा. [illegible]

टी. [illegible]

३७

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
गी॰ अ॰ [illegible]
टी॰ [illegible]
८॰

© Dharmarth Trust. Digitized By eGangotri

गमागन्तुर्दैर्देहं स्थूलं समन्तं त्वतः प्रकृति

गुण ॥ पृथिव्यादिति ॥ पृथिव्यप्तेजोम

मीरश्चन्द्र सूर्येन्द्र [illegible] देवताः ॥ महत्

महत्तत्त्वं स्थूलं [illegible] लोकादयः सृष्टिमात्र

रूपं ॥७॥ पृथिव्यप्तेजोवायु समीरः पृथिव्यादय

घ्राणेन्द्रियं [illegible] समीरः प्रकृति

[illegible] इन्द्रिय [illegible] गन्धः [illegible]

[illegible] विषयः [illegible]

[illegible] इन्द्रियं विषयं

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
गी. भा. टी. ५० [illegible]
[illegible]

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

सूर्ये तिष्ठन्नरैर्नीमवहृभीतिगाह्नः ॥ ७ ॥
हैमकुसंमगीरहृपिडंमहृपमध्यमहुदर
तिकुबसुगीतिहृपिदूवडउपवंतिस्नलः
श्रियगडिडः तिद्वनः भगिसुकुतिगाह्नःस्य
यंभुकमः मेदीलीवः मवहृभी ९७ मरहृ
भीटउः ९७ मरस्य विहृमगिग्नमडेलग
नुमनविहृपुडिविस्नमुलिवसेहुनस्य
हृपिहुमवनजह्नमिडिडवः ॥ ७ ॥ ॐवंद
स्तितिरवजिस्नहुममडिपयेडः भडंडुस्तन

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible] ॥ [illegible] ॥ [illegible]

[illegible] ॥ [illegible]

त्मा ॥१०॥ [illegible]

[illegible]

[illegible]

[illegible]

गी॰ भा॰ [illegible]

टी॰ [illegible]

६३ [illegible] ॥१०॥ [illegible] ॥ [illegible]

© Dharmarth Trust. Digitized By eGangotri

negotiation
lation To
The Swaraj
quite clear
ties in the
ge tha
gai

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible] ॥ दक्षिणे [illegible]
दक्षिणे पिङ्गला नाडी [illegible] ॥ देव-
यानमिति ज्ञेयं [illegible] ॥ [illegible] ॥
[illegible]
[illegible]
[illegible]
[illegible] पिङ्गला नाडी पिङ्गला ना-
डी [illegible]
[illegible]
[illegible] नाडी [illegible] देवयानमिति ज्ञेय-
[illegible] ॥

०३

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible] ॥ दक्षिणे,
दक्षिणे पितृलोकान्तर्गते वह्निमण्डलान्तरं ॥ देव
यज्ञपिण्डं [illegible] ॥ १०० ॥ द
क्षिणे [illegible] वह्निमण्डलान्तरं वह्नि
मण्डलं [illegible]
[illegible]
[illegible] पितृलोकान्तर्गते पितृलोकान्तर
[illegible]
[illegible] देवयज्ञपिण्डे
[illegible] ॥ ००

गी-म.
ली.
८८

© Dharmarth Trust. Digitized By eGangotri

ब्रह्मादिभिर्नतपदकजीवृत्तसमस्त ॥ ३६ ०२
ति ॥ ३७ सदसति: स्तुम्भिमस्तुनीमस्त ॥
पितृपात्रमितिङ्ख्यपवमसाश्रितदिव्यति ॥
तत्रजीवमति: स्तुंभवद्भिमस्तुलंडस्मि
सवमरमायुदमनेमसद्धुमस्तुलंभूत
वमंडामसाश्रितदिव्यज्ञीभवलगरसदहे
वसठात्र: सदस्तुसदवृंत्रपपरतौ
सपितृपात्रमितिङ्ख्यपपुत्रसपञ्चत्रक्रौ
ब्रह्मादिभिर्नतंत्रिलोके: ॥ ०१ ॥ पदवलि

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
गी. भ — [illegible]
टी. [illegible]
५१

© Dharmarth Trust. Digitized By eGangotri

सकभुवनूणगहूमिदिडिठवः ॥ १२ ॥ ॐ ॐः प
ं भुवनूनडीभ्रूयमग ॥ ॐ स्तोति ॥ ॐ भूत्रे
भुविरं भ्रऊं रुजनडीडिभ्रगिठिः ॥ ॐ ॐ पि
नूलयेमत्रेभुवनूभ्रक्षमत्रूपिनी ॥ भवंर
डिभ्रुंयभ्रिजचां भवडेभ्रायम ॥ ॐ सूर्य
नन्तुभ्रूते भवेभ्रकुंभुविरं गहुंवडेडिभयः
ॐ नुडनडीभ्रगिठिः विवेकिठिजनडी
डिवडेनेभूडिपदिकं नडीडिकभूडेडि
भयः ॥ ॐ भवनडीनिज्ञ्ययडि ॥ ॐ डेडि ॥ ॐ

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible] ॥ ०७ ॥ [illegible]

[illegible]

[illegible]

[illegible] मयः [illegible]

[illegible] मयः [illegible] मयः [illegible]

[illegible] मयः [illegible]

यः [illegible] मयः [illegible] मयः [illegible]

गी. भा. [illegible]

टी. [illegible] मयः [illegible]

८१

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible] ॥ [illegible]

[illegible] ॥05॥ [illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible] ॥05॥ [illegible]

[illegible]

63

[illegible]
[illegible]
[illegible] 07
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

नी॰ भा॰ टी॰ ८७ ति॥ भगवतीति॥ भगवती [illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

यस्मात्सूक्ष्मवतीभागी ॥९॥ स्वशिष्यगीति
मेधैर्बद्धिमितिबन्धं विमितत्वमत्वे स्वभा
वतीस्वभावदत्तैर्दत्तलोके तत्र मितिदेवस्य
मत्कृते लोके वद्दद्द मितिमेयः स्वयं मितिमत्कृत
क्रियान्तरे वेदवतीन भगी विस्तुसिद्धः स्वश्रि
लोकेऽत्र मितिदेवस्य मत्कृते लोके वद्दत्त मितिमेयः ९
किं पद्यश्वेति ॥ पद्यमन्यमिति सूक्ष्मपमलोके
सूक्ष्मितिस्वतः ॥ नेवेतेन वद्धस्व नेते लोकेत्र
स्मृतः ॥१०॥ सहस्वेदमिति कल्पेपद्यप

© Dharmarth Trust. Digitized By eGangotri

मध्वज्ञिनीमंयमिष्टाप्वेयमल्लेकः यमादिये
वन्मकुर्डियमल्लिकः ध्रुविष्णुर्मीरितः ।
डद्दद्रेमह्निल्कन्ठनेनैदः नितडिमधुक्ति
नीनैद्दप्तेल्लेक व्रमिर्डिमीरितः ॥११॥ किं
स ॥ विश्ववसीति ॥ विश्ववसीधूतीप्रा डद्दर्ध्रुवन
लिकरूधरी ॥ वायेनद्धववीकन्ठपाप्रेल्लेकः
तिष्णुतः ॥१२॥ धरीष्टंधस्त्रिमाधिमिधर्ध्रुम
नी. म. स्त्रिमठनेविठवरीमंक्षिक्रावनलिक्राभगी
पु. वन्मवज्ञिनीधरीवडतेडिमेयः। कन्ठपत्रे
प.

© Dharmarth Trust. Digitized By eGangotri

𑆑𑆩𑆑𑆬𑆳𑆩𑆪𑆵𑆩𑆴𑆠𑆠𑆶𑆫𑆘𑆵𑆥𑆢𑆥𑆿𑆢𑆥𑆶𑆬𑇀𑆬𑆼

𑆑𑆂𑆱𑇀𑆯𑆴𑆠𑆴𑆱𑇀𑆯𑆴𑆠𑆴𑆯𑇀𑆫𑆵𑆲𑆽𑆂॥𑇑𑇗॥𑆱𑆴𑆢𑇀𑆣𑆴॥

𑆱𑆴𑆢𑇀𑆣𑆥𑆢𑆘𑆵𑆱𑆴𑆢𑇀𑆣𑆴𑆱𑆴𑆩𑆬𑇀𑆬𑆼𑆑𑆥𑆶𑆑𑆛𑆂

𑆬𑆑𑆬𑆁𑆠𑆢𑆴𑆠𑇀𑆪𑆪𑆼𑆱𑆼𑆤𑆳𑆱𑆴𑆢𑇀𑆣𑆴𑆯𑆶𑆢𑇀𑆣𑆴 𑇑𑇘

𑆱𑆴𑆢𑇀𑆣𑆥𑆑𑆳𑆱𑆴𑆱𑆴𑆑𑆛𑆂𑆑𑆛𑆱𑆼𑆱𑆳𑆱𑆲

𑆑𑆩𑆑𑆬𑆁𑆑𑆳𑆩𑆱𑆴𑆢𑇀𑆣𑆴𑆱𑆴𑆢𑇀𑆣𑆴𑆑𑆫𑆩𑆢𑆶𑆮𑇀𑆫𑆵

𑆥𑆵𑆥𑆢𑆘𑆵𑆥𑆢𑆲𑆳𑆥𑆽𑆂𑆱𑆴𑆩𑆬𑇀𑆬𑆼𑆑𑆼𑆑𑆳𑆩

𑆱𑆼𑆤𑆳𑆱𑆴𑆢𑇀𑆣𑆴𑆯𑆶𑆢𑇀𑆣𑆵𑆠𑆴𑆢𑇀𑆪𑆪𑆁𑆂॥𑇑𑇘॥𑆑𑆴𑆁

𑆱𑆑𑆱𑆼𑆠𑆴॥𑆑𑆳𑆩𑆱𑆑𑆶𑆱𑆴𑆱𑆼𑆱𑆳𑆫𑆵𑆱𑆴𑆢𑇀𑆣𑆬𑇀𑆬𑆼𑆑

© Dharmarth Trust. Digitized By eGangotri

𑆩𑆚𑇀𑆠𑇀𑆫𑆴𑆟𑆵 𑇅 𑆥𑇀𑆫𑆡𑇀𑆫𑆴𑆮𑆲𑇀𑆚𑆩𑆓𑆵𑆤𑇀𑆢𑇀𑆫𑆪𑆳𑆮𑆸𑆢𑇀𑆣𑆳𑆢𑇀𑆫𑆶𑆩
𑆑𑆩𑆫𑇀𑆥𑇀𑆫𑆴𑆪𑆼𑆪𑆴 𑇅𑇒𑇑𑇅 𑆮𑆳𑆩𑆼𑆩𑆑𑇀𑆫𑆶 𑆥𑆴𑆮𑆩𑆚𑆼𑆢𑇀𑆮𑆶
𑆩𑆚𑆵𑆱𑇀𑆠𑇀𑆫𑆳𑆩𑆱𑇀𑆮𑆴𑆠𑇀𑆫𑆵𑆩𑆚𑇀𑆠𑇀𑆫𑆴𑆟𑆵𑆩𑆚𑇀𑆠𑇀𑆫𑆢𑆼𑆮𑆳𑇃 𑆱𑆴
𑆮𑆩𑆼𑆑𑇃 𑆱𑆴𑆮𑆮𑆩𑆑𑇀𑆫𑆶𑆩𑆼𑆑𑆼𑆤𑇀𑆢𑇀𑆫𑆪𑇃 𑆥𑇀𑆫𑆡𑇀𑆫𑆴𑆱𑆴
𑆓𑆱𑆴𑆮𑆲𑇀𑆚𑆓𑆵𑆮𑆲𑇀𑆚𑆩𑆼𑆑𑆼𑆤𑇀𑆢𑇀𑆫𑆪𑇃 𑇅 𑆤𑆮𑆁𑆮𑆢𑆁
𑆩𑆮𑆁𑆑𑆚𑆢𑇀𑆢𑆁𑆢𑆼𑆑𑆁𑆱𑇀𑆥𑆴𑆁𑆢𑆼𑆑𑆤𑆮𑆮𑆢𑆢𑆢𑇀𑆢𑇃 𑇒𑇑
𑆢𑆼𑆢𑆼𑆩𑆼𑆑 𑆥𑆴𑆑𑆩𑇀𑆣𑆚𑆩𑆤 𑇅 𑆤𑆢𑆥𑆴𑆢𑆴𑆪
𑆢𑆢𑆤𑇃 𑆱𑆴𑆢𑆼𑆚𑆢𑇃 𑆑𑆩𑆥𑆴𑇃 𑆫𑆩𑆪𑆳𑆢𑆑𑇃
𑇑𑇐 𑆩𑆚𑆩𑆪𑆩𑆤𑆱𑇀𑆮𑆶𑆱𑇀𑆮𑆶𑆁𑆩𑆢𑆩𑆢𑆢𑆴𑇃 𑆱𑆴𑆮𑆱𑆴𑆢𑆴

𑆤𑆵𑇆𑆩𑆫𑇆 𑆢𑆵𑇆

𑇒

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible] [illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible] [illegible]

[illegible] [illegible]

[illegible] [illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible] || [illegible]

[illegible] || [illegible]

[illegible] || [illegible]

[illegible] || [illegible] || [illegible]

[illegible] || [illegible] || [illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
गी० भा० [illegible]
टी० [illegible]
७३ [illegible]

© Dharmarth Trust. Digitized By eGangotri

𑆱𑆝𑆴𑆨𑆶𑆘𑇀𑆚𑆵 𑆲𑇀𑆫𑆷𑆂 𑆱𑆼𑆮𑆁 𑆩𑆩𑆱𑆶𑆩 𑇆 𑆥𑇀𑆫𑆢𑆩𑆽𑆩𑆝𑆴 𑇆
𑆥𑇀𑆫𑆢𑆩𑆽𑆩𑆥𑆶𑆤𑆑 𑆲𑆁𑆮𑆟𑆱𑆶𑆫 𑆤𑆠𑇀𑆫𑆴𑆂 𑇆 𑆩
𑆱𑇀𑆫𑆶𑆩𑆥𑆶𑆩𑆽𑆲𑆾𑆪𑆼𑆱𑆶𑆮𑆼𑆠𑆂 𑆥𑆶𑆤𑆬𑆼𑆑𑆣𑆂 𑇆 𑇕𑇐
𑆥𑇀𑆫𑆢𑆩𑆽𑆩𑆲𑆢𑆴𑆥𑇀𑆫𑆢𑆢𑆴𑆫𑆤𑆑𑆲𑆴𑆩𑆶𑆥𑆳
𑆥𑇀𑆫𑆁𑆱𑆶𑆮𑆼𑆠𑆣𑆝𑆴𑆥𑆶𑆤𑆬𑆼𑆑𑆥𑆳𑆠𑆼𑆱𑆮𑆼𑆮𑆣𑆣 ॥
𑆲𑆶𑆂 𑆥 𑇆 𑆥𑆮𑆁𑆑𑆬𑇀𑆪𑆤𑆣𑆬𑆩𑆴𑆣 𑇆 𑆲𑆪𑆼𑆝𑆴
𑆲𑆪𑆼𑆑𑆬𑇀𑆪𑆪𑆼𑆠𑆵𑆣𑆩𑇀𑆲𑆴𑆑𑇀𑆮𑆮𑆥𑆁𑆬𑆣𑆼𑆣
𑆲𑆪𑆥𑆳𑆩𑆣𑆬𑆼𑆑𑆁𑆤𑆼𑆬𑆼𑆑𑆁𑆑𑆣𑆂 𑇆 𑇕
𑆥𑆼𑆬𑆼𑆑𑆁𑆲𑆮𑆼𑆢𑆼𑆤𑇀𑆫𑆴𑆩𑆲𑆁𑆫𑆝𑆴𑆨𑆶𑆣𑆩𑆝𑆴 𑇆 3

© Dharmarth Trust. Digitized By eGangotri

योगी हृदये [illegible] प्र[illegible] [illegible] क्ष्मीनिक

न्यस्य [illegible] हृ[illegible] [illegible] मेव [illegible] भव

[illegible] ऽऽ [illegible] [illegible]

[illegible] हृदय[illegible]ति ॥ हृदय[illegible] मेव: ॥

[illegible]

[illegible] : ॥ हृ[illegible] [illegible]

नी. अ.
टी.
१८

[illegible] क: स्थि[illegible] ॥ ८७

[illegible] ऽ [illegible]

[illegible] ॥ हृ[illegible]ति ॥ [illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

वाऽमाक्रमं नीयमाने ऽपदेयध ॥ अदेन्द्र

ऽतक्रमं ऽस्तुष्णीवः सन्ति ॥ अदेनीयमा

नेऽप्रवदेमा सत्रमेमं स्रमाने ऽपदेन भूयध

अपक्रमं भक्रमेपेतं स्रोतऽऽस्तूष्णीकः

भामक्षीतः ॥ अपक्रममिति ॥ अपक्र

ममिवक्षनं विलयं वेऽऽस्तुतः ॥ मन्त्रऽि

ति लक्षं स्तुत्लोतं नमं मध ॥ ६७ ॥ ध१

स्तुक्षं नमीवं अपक्रममिवमक्रमेभाम

क्षतिलयं नऽस्तुक्तयधजः पूर्वेऽस्तुनं ति

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible] 𑇈 𑇑𑇐 𑇈 [illegible] 𑇈
[illegible] 𑇈 [illegible]
[illegible] 𑇈 [illegible]
[illegible] 𑇈 𑇑𑇐 𑇈 [illegible]
[illegible]
[illegible] 𑇅 [illegible]
[illegible]
𑆓𑆵𑇆 𑆨𑆳𑇆 [illegible] 𑇈 𑇑𑇐 𑇈 [illegible]
𑆜𑆵𑇆 [illegible] 𑇈 [illegible]
𑇑𑇑

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

गी. भा. टी. ७५ [illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

𑇁𑆫𑇀𑆡𑆩𑆫𑇀𑆩𑆘𑇀𑆚𑆾𑆩𑆤𑇀𑆠𑇀𑆫𑆢𑆼𑆮𑆩𑆴𑆯𑇀𑆫𑆶𑆠𑆼𑆤𑆳𑆛𑇀𑆛𑆲𑇀𑆛𑆰𑆯𑇀𑆫𑆶𑆬
𑆠𑆡𑆳𑆣𑆪𑆳𑆠𑆴𑆤𑆳𑆩𑆴𑆠𑆴 𑇆𑇘 𑆠𑆴𑆯𑇀𑆫𑆵𑆪𑆾𑇁𑆪𑆩𑆩
𑆢𑆣𑆴𑆓𑆩𑆴𑇁𑆪𑆁𑆩𑆓𑆤𑆵𑇁𑆤𑇀𑆲𑆳𑆱𑇀𑆠𑆥𑆪𑆳𑆁𑆑𑇀𑆰𑆴𑆠𑆵𑆥𑆾𑆰𑇀𑆛
𑆪𑆂 𑇆𑇙𑇆 𑆪𑆾𑆓𑆵𑆲𑆘𑆑𑇀𑆰𑆴𑆪𑆳𑆬𑆩𑆥𑆳𑆫𑆴𑆲𑇀𑆟𑆼𑆤𑆩
𑆠𑇀𑆫𑆶𑆟𑆵𑆂 𑇆 𑆲𑆬𑆵𑆪𑆩𑆓𑆳𑆁𑆥𑆥𑆲𑆶𑆩𑆴𑆢𑆠𑆴𑆑𑆵𑆲
𑆠𑆼 𑇆 𑆯𑇀𑆫𑆵𑆤𑆳𑆡𑆤𑆷𑆢𑆤𑆩 𑇆 𑆱𑆤𑆠𑆩𑆱𑆶𑆁𑆧𑆑𑆮𑆼𑆩𑆴
𑇁𑆲𑆁𑆩𑆤𑇀𑆠𑇀𑆫𑆱𑇀𑆫𑆑𑆳𑆬𑆽𑆮𑆠𑆮𑆱𑇀𑆫𑆢𑆴𑆩𑆳𑆂 𑇆 𑆥𑆲𑆷𑆥
𑆑𑆶𑆁𑆠𑇁𑆑𑆶𑆥𑆩𑆴𑆠𑆲𑆁𑆠𑆁𑆩𑆽𑆪𑆥𑆯𑇀𑆫𑆵𑆓𑆩𑆴𑆮𑆯𑇀𑆫𑆶𑆩𑆴
𑆮𑆯𑇀𑆫𑆶𑆩𑆴𑆱𑆶𑆩 𑇆𑇐𑇆 𑆮𑆴𑆮𑆼𑆑𑆴𑆤𑆳𑆪𑆾𑆓𑆴𑆤𑆩𑆳𑆑𑆶

© Dharmarth Trust. Digitized By eGangotri

[illegible]

गी. भा. टी.

१७

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible] || [illegible] || [illegible] || [illegible]

[illegible] || [illegible]

[illegible] || [illegible] || [illegible]

[illegible]

[illegible]

[illegible] || [illegible] || [illegible]

[illegible] || [illegible] || [illegible]

© Dharmarth Trust. Digitized By eGangotri

लीविडंनपिमद्वलभा ॥ शिढंयम

भूल्लत्रियद्धंटंडुपञ्च — —

— — — — क्ष्टं

भूडम ॥ ८ ॥ श्वमाटः

क्षमगडिडंमडुमन्हकमद्धंविड्डय

स्रवेरन्नाडुंलीविडमपिमाश्चलंविड्डय

मगमश्वंमवेलयंयद्धूटंमवमन्नुमिदिः

त्रुयक्षहूल्लत्रिविनयययद्धंटंडमेवँ

पमूडमिविडिठवः ॥ ६ ॥ उंड्वियल्पेम

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible] 1

[illegible]

[illegible]

[illegible]

गी॰ भा॰ टी॰ १०

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]
[illegible] ॥ [illegible]
[illegible] ॥५॥ [illegible]
[illegible]
[illegible] ॥ [illegible]
[illegible] ॥६॥ [illegible]
[illegible] । [illegible] ॥ [illegible]
[illegible] ॥ [illegible]
[illegible] ॥७॥ [illegible]

© Dharmarth Trust. Digitized By eGangotri

तियदृष्टिषयीकृतोऽतिऽरुऽरुपानंमवेदृहुपं
रुपादंयुष्टुरुऽरुमवरुपांशद्धेवमभवस्त्रितुंप
दः स्फुटीकृतसिद्धरुत्तरनदसिद्धिभवः ॥ १
पऽदमद्रुयैतिन: मवमपिद्रुदृष्टाऽयत
मडेतडन ॥ दद्गुरुतेऽति ॥ दद्गुरुतेदमिकृप
सिन्नन्तंनतितिदलम ॥ खनमिदृष्टांह
दपानंविष्णुमहायसिद्धि ॥१०॥ पानंमवे
हृहृमहदंस्रांखपसयगतिडं खहयंन
सातिडं विष्णुंपमरुहृनं खनमिहदेदे

गी. भ.
टी.
१३

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
नी॰ म॰ [illegible]
टी॰ [illegible]
१८

© Dharmarth Trust. Digitized By eGangotri

𑆯𑆿𑆁𑆱𑆩𑆳𑆫𑆷𑆁𑆯𑆽𑆑𑆳𑆫𑆳𑆬𑆳𑆠𑆴𑆤𑆁𑆯𑆽𑆑𑆩𑆳𑆤𑆼𑆑

𑆫𑆷𑆁 𑆱𑆥𑆮𑆤𑆱𑆴𑆠𑆴𑆮𑆳𑆬𑆳𑆯𑆽𑆑𑆳𑆥𑆳𑆥𑆢𑆑𑆁𑆥𑆳𑆩𑆶

𑆑𑆷𑆁𑆮𑆴𑆯𑆶𑆁𑆲𑆥𑆑𑆩𑆢𑆶𑆁𑆤𑆩𑆓𑆴𑆁𑆩𑆮𑆝𑆽

𑆝𑆳𑆑𑆳𑆁𑆩𑆶𑆮𑆁𑆥𑆑𑆩𑆁𑆩𑆮𑆑𑆶𑆝𑆳𑆥𑆴𑆮𑆳𑆩𑆴𑆤𑆁𑆩𑆮

𑆠𑆶𑆝𑆴𑆪𑆩𑆑𑆁𑆩𑆼𑆤𑆑𑆳𑆁𑆑𑆁𑆩𑆢𑆑𑆁𑆢𑆴𑆩𑆴𑆠𑆶𑆪𑆼𑆑𑆶

𑆪𑆼𑆝𑆳 𑇆 𑇐𑇓 𑇆 𑆥𑆢𑆁𑆢𑆴𑆩𑆴𑆠𑆶𑆪𑆴𑆝𑆂 𑆥𑆥𑆬𑆼𑆥𑆤𑆳𑆯𑆵

𑆲𑆤 𑇆 𑆱𑆢𑆁𑆢𑆽𑆝𑆴 𑇆 𑆱𑆢𑆁𑆢𑆽𑆝𑆴𑆪𑆂𑆩𑆮𑆁𑆮𑆴

𑆩𑆤𑆳𑆝𑆴𑆤𑆳𑆂𑆩𑆤 𑇆 𑆤𑆢𑆑𑆶𑆪𑆩𑆴𑆩𑆑𑆶𑆩𑆤𑆮

𑆩𑆵𑆩𑆮𑆢𑆴𑆑𑆶𑆪𑆵 𑇆 𑇐𑇘 𑇆 𑆩𑆮𑆁𑆠𑆴𑆩𑆴𑆑𑆶𑆁𑆢𑆑𑆥𑆴𑆑𑆯𑆽

© Dharmarth Trust. Digitized By eGangotri

𑆱𑇀𑆩𑆫𑆤𑇀𑆠𑆼 ॥ 𑇐𑇘 ॥ 𑆪𑆂 𑆱𑆫𑇀𑆮𑆢𑆳 𑆱𑆫𑇀𑆮𑆑𑆬𑇀𑆪𑆳𑆟𑆁 𑆢
𑆢𑆳𑆠𑆴 𑆯𑆴𑆮𑆫𑆹𑆥𑆴 𑆱𑆫𑇀𑆮𑆫𑆹𑆥𑆴 𑆱𑆑𑆬𑆁 𑆯𑆴𑆮𑆯𑆴𑆮𑆼𑆠𑆴
𑆱𑇀𑆩𑆸𑆠𑆴 𑆥𑆴𑆱𑆫𑇀𑆮 𑆯𑆴𑆮𑆯𑆴𑆮𑆼 𑆫𑆼𑆮 𑆥𑆴𑆫𑆥𑆴 𑆠𑆱𑇀𑆩𑆳𑆑𑇀𑆱𑆩𑆳
𑆤𑆴𑆮𑆩𑇀𑆤𑆳𑆢𑆳𑆤𑆳𑆪𑆼 𑆢𑆹𑆮𑆁 𑆯𑆴𑆮𑆯𑆴𑆮𑆁 𑆑𑆩𑆢𑆫𑆹𑆥𑆴
𑆠𑆼𑆯𑆴𑆮𑆯𑆴𑆮𑆁 𑆑𑆩𑆢𑆴𑆤𑇀𑆢𑇀𑆫𑆱𑆹𑆠𑆼𑆱 ॥ 𑇐𑇘 ॥ 𑆪𑆳𑆬 𑆱𑆳𑆫𑆁𑆢
𑆫𑆹𑆥𑆳𑆤𑆫𑆠 𑆱𑆳𑆤𑆳𑆑𑇀𑆫𑆹𑆥𑆁 𑆯𑆴𑆮𑆥𑆢𑆴𑆝 𑆤 ॥ 𑆯𑆴
𑆯𑆴𑆮𑆯𑆴𑆮𑆼𑆠𑆴 ॥ 𑆠𑇀𑆫𑆴𑆯𑆴𑆒𑆁 𑆠𑇀𑆫𑆴𑆯𑆴𑆒𑆁 𑆖𑆁𑆢𑇀𑆫𑆩𑆾𑆭𑆴𑆩𑆾𑆭𑆴 𑆠𑇀𑆫𑆴
𑆮𑆳𑆬𑆩𑆳 ॥ 𑆱𑆩𑆬𑇀𑆤𑆳 𑆢𑆼𑆮𑆱𑆼𑆮𑆼 𑆤𑆠𑇀𑆫𑆴 𑆮𑆴𑆤𑆢𑆼𑆂 𑆑𑆴𑆁𑆫
𑆢𑆼𑆮𑆤𑆩𑆳 ॥ 𑇐𑇑 ॥ 𑆩𑆾𑆭𑆴𑆩𑆾𑆭𑆴 𑆠𑇀𑆫𑆴𑆮𑆳𑆬𑆁 𑆪𑆱𑆮𑆤𑆼𑆢

𑆓𑆵. 𑆩. 𑆢𑆵. 𑇗𑇑

[illegible]

© Dharmarth Trust. Digitized By eGangotri

नक्षित्रयथोक्तं सिद्धिदः ॥ वसंतपञ्चमी दिवि
रजोत्कं सिद्धये त्रपुरुष्कृत्य । नमस्तं भज
भवन्तं दिग्विजयं समतं कंमन्त्रोक्तं सर्वभ
न्यायदिह्न सिद्धये न ॥ १ ॥ किं सकृत
रति ॥ कृतवसुदेमे सिद्धे धनलक्षणादिहरे
रति ॥ १० ॥ कृतवसुविकल्पनमं त्रिनवव
सुति वमेषु दुग्धधेनु दिविज्ञः सर्वादिहेनि
तु ज्ञानवतः मन्त्रा । प्रणामिवसुविधि
पद्मासमिद्धे वस्मानवसुविदितमेहुन्दस्याद्धि

नी. भ.
गी.

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

[illegible]

زاغ اپان شُمم گرتھ تہ وپان شُمال یِنی

تُو شُفت تہ گیاہ گو یلہ مَن پھ منتر زِنُ تِوہ تھ

پیھوی منتر یلہ کُس مَن زِنُ تہ مَن اچھہ پیتھر

نشر نِت چھہ وپان منبود آسی سِنُہ شتلاوی

[illegible] نبر ادہ یلہ شُند اچھہ

چھہ ہنت وپان سا [illegible] کار

[illegible] بگرو تُرتھم اشنب سجوم شُبل نُد

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

राम गीता

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible] ॥ ३ ॥

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

डमन्नीक्षनष्टैवभेकफेडउंवजेक्षनकमभभक्षुयवानं
ध्रुषण्यन्नुवमुउ नहिउि यषाविष्टवेमभायनवृक्ष
विमुश्रेउिथाभिष्टनमिन भजघाजभाषानभक्तउषेठ
इभेव थज्ञाहंयषाविथमिणुगउिः उमेवक्षनकमष्ठुं

भूषृउवृक्षमा
शुम नन्दिप्रियन्वेदमभावेनमेमिउ
कुयं मुउभिष्टनादि

नन्दिप्रियपुपिउक्षयनदुनेज किंमुावष्टककउहउया

भूमेमिउ
निष्टयेभिउि
यद्वैवविष्णुभुमघाजभयनभा
कउभाहिया

शुभीयडभूषभा। एवंमभमकालभूहवाम्येदुहु
क्षुवैदुउिरव
कउहउभूलाहउभूमेमिउ
नष्टेणुडम्
भएल्लननीयय
क्षभनाचिन्तयाःभकयदंभश्रेउि
षामडमभू
क्रिय मीनंधाम
भूपेतिभभूः२म००
विष्णुभक्तयदुभ
रुयउ॥००॥

७

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

उमामहेश्वरौ वन्दे ... विष्णुर्विरिञ्च ...

विरिञ्चिर्भगवान्येन रुद्रः ... सर्वपापापहः ...

... इति निगदतः सर्वसिद्धिप्रदो ...

... सर्वदा ...

अन्तःकरण ... सर्वपापैः प्रमुच्यते

विष्णुर्विरिञ्चिर्भगवान्येन रुद्रः

अङ्गुष्ठमात्रपुरुषः सदा वि

७

तौ भैरववज्रियवत्रोणमः ७

इति

© Dharmarth Trust. Digitized By eGangotri

मविष्णुय गुह्मनम

यवस्मगीर ऽमिमभायर्यैरुणी मतिविनापिस्वै नऽनुहऽनुउठ उऽट्टन यवलि

उि विपिटलतुहुमिमूउि: वामःनुउहुउरेपक: पथंकम्प विं पीसेवहुवडी

भुवद्भिणिंदिविणिवभकम् एक्कुउठवउा

मघाउ मुम्पैमेनुहुमिवह्नैः गपिलंयणत्रिषिष्ठहुमिष्टाहुनावि ष्टीयउभिलय

स्मेउिवन्नैःगपिलंनिषिष्टुउ उया भट्टहुनथा म्हुहु पंह्मह्मारि यस्मुलउा ॥१॥

धूधपरस्मनमष्टुलद्भियः १

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

भगवान्उवाच वीरं
वाम्बाउविपत्रपमंत्र
वेणप्रचककुभग
समगवितउ
इइपमक्ष्य
इत्थुभभीतिडइ
इत्थुमन्त्रः भच

खवमंमाइमिइतुं
भगवाह्माउइत्थहदुउ
क्षमामिरगदितेन

उत्तिपमन्त्रवणाउद्विकालं

वाम्बाउविक्षवविणविणचउः क्षजामि
पुलः पाभक्ष

कुंपमन्त्रेल्यस्तोरवीवः उतुंपमयैरकातुंउडेणकम
भीतिपमभा ॥
उतुंपमके पाभक्षरवीवक
१५ ॥ १५ ॥
॥

वभीतिमेकुभबान्यिबुवेग १५

३

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible] 33

[illegible]

[illegible]

[illegible] || 33 ||

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

3

© Dharmarth Trust. Digitized By eGangotri

[illegible]

॥ ३७ ॥

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

स्वच्छनिर्मलतत्त्वेकीदृशे, तत्त्वे निभितं उत्थ, त भवावि
कल्पकाल भ्यागमिति मिद्धं पिभवकाले निरभय
मापस भक्ति, स्वभयकेव ले भवविकारमुक्ते पा
मद्दविलय, ले वृक्षलिष्ट पके स्वच्छनिर्भूषमभक्ष्णः
कालिदः भा॰
वस्मः स्व विकल्पभ्यागमिति मिमट्क
स्वच्छृक्के, स्माप्व भवकाल मिति ठवः ॥

कक्षाप्य भूषमः भूकालिदः

पक्षभाप्य वृक्षिभवकालेनि

गं.
नी.
भु.

रभयवृक्षालिकेवलधारे ३३

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

ह्ल्यं निरूपाणि भुक्तं स्तोकद्येनाह भकमस्तुपः
प्रभकमः मलिनम्नलिविकारदीन मन्त्रियः प
मिभलीनः मभज्ञ्विठ्ठः भक्तमपिठभक्तात्र
नविठ विठः नवस्तु भयत्रेह ऽङ्ह्रेः ॥

भकमस्तुपेठभठ्ठभत्रय:
त्रियि

भयत्रुतवाल
विकपाकि
भज्ञ्विठ्ठेठभत्रीवनिमल: ठः

विमुत्तुमिम्नकामः कठ्ठक्ष्ठिभानमुत्रः

विभक्तुविहूनभयेनिरभय: मेमकाल
वत्रुपमिक्कम
मुत्रः ॥

त्रुयः
भक्तत्रनन्नभयेठभात्रियः म३
भल्त्रीय विमरणी
यांठिठः ॥

© Dharmarth Trust. Digitized By eGangotri

सनत्कुमारः [illegible] कल्पान्तमार [illegible] यत्नेन [illegible]
सकलपरिमुक्तमनुवृत्तः [illegible] यः [illegible]
प्रियं [illegible] ८८ ॥

कल्पद्वये पि

[illegible]

[illegible]

सं॰
नी॰
३३ [illegible] ८८

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]
[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]
[illegible]
[illegible]
[illegible]

[illegible] [illegible]
[illegible]

[illegible] [illegible]
[illegible]
[illegible]

[illegible] [illegible]
[illegible]
[illegible]

[illegible] [illegible]

© Dharmarth Trust. Digitized By eGangotri

यथा विलायन भक्ता भग विश्वभित्तिं तन्त्राणव
भित्तिं भुक्तिफलनिग्रहं न भुक्तिविभागमनेन भित्तिं विश्वं
भक्तं ... भक्तं भवविलायये। उत्तम ...
... जगत् विलीनं तद्वयेत्
भक्तं ... विश्वं भक्तं भक्तं विलायये
भूत्वाद्वितीय
तत्त्वं भक्तं विलीनविश्वं भक्तं विलीनं तद्वयिद्वयः
१०॥

भक्तं भवतु तत्त्वार्णवभित्तिं

उत्तभक्तं विलयं ...

वा.
मी.
३

श्रीयत्तत्त्वं ... १.

© Dharmarth Trust. Digitized By eGangotri

[illegible]

५०॥

[illegible] ५०

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

यंस्मत्सर्वभक्तप्रियं तत्त्वं देवदेवं एवमिति शिवः कृपया
यद्भक्त्यैव विधयेश्वरः कृपालु [illegible] श्रुतिः [illegible]
भवस्य [illegible] निरञ्जनं निरञ्जनं विष्णुं पद्मं [illegible] निर्मल
[illegible] पितृपाः पद्मं [illegible] मन्त्रं [illegible] वर्मीलिते
यन्त्रं भग

एवं भगवन्नुमा भवापि येनिवे [illegible] समिद्धेय
मा ७३॥
नैमित्तिः मन्त्रस्य विधयः॥

निकटं भवे विद्धि येन मया श्रुति

विनिर्मितं मेधपीठकं भग

श्रीश्चेत्थं सिन्दुरसर्वस्वः ७३

© Dharmarth Trust. Digitized By eGangotri

𑆯𑇀𑆫𑆵𑆮𑆓𑇀𑆱𑆠𑆾𑆂

𑆅𑆢𑇀𑆝𑆮𑆨𑆳𑆑𑇀𑆱𑆤𑆩𑆳𑆑𑆴𑆤𑆴𑆩𑆁𑆓𑆴𑆮𑆴𑆬

𑆧𑆴𑆑𑇀𑆱𑆥𑆨𑆾𑆩𑆩𑆫𑆮𑆫𑆳𑆱𑆂 𑇕

𑆥𑇀𑆫

𑆮𑆶𑆩𑆱𑇀𑆫𑆳𑆠𑆴𑆑𑆴𑆩𑆳𑆤𑆮𑆬𑇀𑆪𑆼𑆠𑆩

𑆩𑆑𑇀𑆭𑆼𑆥𑆑𑆮𑆠𑆵𑆓𑆂

𑆫𑆂 𑆯𑇀𑆫𑆵𑆂 𑇑𑇓 𑆪𑆑𑆨𑆳𑆑𑆳𑆢𑇀𑆢𑆶𑆮𑆴𑆬𑆵𑆪𑆠𑆼𑆠𑆂 𑇑𑇕

𑇓𑇓

© Dharmarth Trust. Digitized By eGangotri

[illegible]
[illegible]
[illegible] ॥
[illegible] ॥

[illegible]

[illegible]

[illegible] ॥

[illegible]

[illegible]

॥

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

𑇄𑆪𑆑𑇀𑆰𑆵𑆑𑆴 𑆠 𑆑𑆴𑆬𑆻𑆑𑆁𑆯𑆴𑆠 𑆱𑇀𑆤𑆳𑆤𑆩𑆴𑆱𑇀𑆛
𑆱𑆶𑆓𑆤𑇀𑆣𑆑𑆶𑆑𑆶𑆩
𑆓𑆤𑇀𑆣𑆮𑆳𑆱𑆴𑆠
𑆪𑆳𑆑𑆴𑆤𑆶𑆥𑆳𑆑
𑆱𑇀𑆤𑆳𑆤𑆩𑆣𑆮𑆴𑆠 𑆮𑆴𑆑𑆫𑆮𑆪𑆩𑆶𑆤𑆴𑆂 𑆤𑆠𑆂 𑆥𑆶𑆱𑇀𑆥𑆳𑆬
𑆠𑆴𑆤𑆴𑆫𑆳𑆑𑆶𑆠𑇀𑆪𑆢𑆶𑆫𑆳 𑆢𑆶𑆱𑇀𑆠𑆢𑆶𑆫𑆳𑆠𑆂
𑆪𑆑𑇀𑆰𑆑𑆫𑇀𑆢𑆩𑆂
𑆤𑆴𑆫𑆳𑆑𑆶𑆠𑇀𑆪𑆢𑆶𑆫𑆳𑆠𑆴 𑆪𑆑𑇀𑆰𑆴𑆨𑆳𑆮𑆻𑆠 𑆱𑆑𑆶𑆩𑆑𑆴𑆱𑇀𑆠𑆴
𑆩𑆑𑆶𑆫𑆮𑆴𑆩𑆂
𑆢𑆑𑆑𑆮𑆑𑆱𑆤𑆤𑆴𑆪𑆮𑆠 𑇆

𑆪𑆑𑇀𑆰𑆑𑆫𑇀𑆢𑆩𑆻𑆱𑆴𑆱𑆴𑆩𑆑𑆨𑆳𑆩𑆪𑆂 𑆕𑆓

[illegible]

3

© Dharmarth Trust. Digitized By eGangotri

राम गीता

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

3

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

एवंरीत्या शिवभक्तलक्षणं कथयन्नाह यः इति

[illegible]

यः शिवे तं समं मत्वा गुरुं देहम्

[illegible]

[illegible]

[illegible]

रा॰ [illegible]

ती॰ [illegible]

३० [illegible]

८०

ऽन्तरी सेतद्गुरुर्त्वास्यत्तसमस्तुष्टु
यं सन्तीति पितुर्वल्लसन्न विष्णु
नभिति

विष्णुवल्लभकं

विष्णुर्वै सत् सर्वपिलेस्मृतिमानसे

वेदान्तेषु पविधनुर्हे वर्हसनं सम्यग्ज्ञाति ल्लय

सर्वं वेदान्त वेद्यमानलं वसय्यैवनीतं तं कुसयत्ते तेनसय ॥

यः सृष्टय पालि पंश्रुतिकान्तियन्ते

सृष्टय सेतियाति सद्वसन्तेषु ठन्ति यः

सर्वं वसे सल्लसनः श्रुविलीयन्ते ॥३॥

ननयं सर्वं सन्ते उत्पद्यस सदृल्ल भूतभिक्षुष मितु न य
नीति सन्तोजैवसनेषु लिसुन्ने यस्नीदाः उत्पन्नावि
सर्वाश्रैवकल्लसयकतु ... यः ॥१॥

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

तेजोबिन्दूपनिषद्

ॐ

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible] ॥१॥ [illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

त्रिभुवने वर्त्ति पुरुषः अष्टाङ्गान्येकेनापि
सति भावः पृच्छकस्य [illegible] प्रथमः
प्रश्नः १ अथ [illegible] पृच्छः अष्टाङ्गा-
न्येकेनापि सति भावः [illegible] पृच्छका-
नाम् द्वितीयः प्रश्नः ॥ २ ॥ यत्र स्थित्वा
नरः पृच्छकः अकस्मात् नरः पृच्छति
[illegible] ॥ [illegible]
एकेनापि पृच्छन् [illegible]
[illegible] पृच्छकः सति भावः पृच्छ तृतीयः
हिं० प्रश्नः ॥ ३ ॥ एवं चेत् [illegible] एवं
[illegible]
[illegible] ॥ ४ ॥

ग्रुः स्रूं नवक्तिः स्रूं मेठयतः
स्रूं नस्रूरयां नस्रूं नुस्रूं
मा ससस्रुस्रुहवरूदसृरूसृल
कल सृसितु सुरुपञ्जसृसकञ्ज सह
यसां सुपञ्जपसस्रं सतुंसिवस
स्रुतं सतुंस सतुं सञ्जसावि
यः । १ ॥ सृय सुञ्ज स्रु मा सुकि
पिसां यरू सारु सार्ञ्ज सरू
यकार उकारे मकार डोउ ॥ ३ ॥
पिउ सृने वैश्वानरुकारः सष सा
सृयुसि सङ्गसुस्रेति जवें सचानी
कसातुसिस्रुरु भवति यातं वरु ॥ ४ ॥

© Dharmarth Trust. Digitized By eGangotri

अथ [illegible] द्वितीय [illegible]
[illegible]
[illegible]
[illegible] भवति य एवं वेद ॥ १० ॥ अथ [illegible]
[illegible] तृतीय [illegible]
[illegible]
[illegible] भवति य एवं वेद ॥ ११ ॥ [illegible]
[illegible]
[illegible]
य एवं वेद य एवं वेद ॥ १२ ॥ ॥
[illegible] इति [illegible] ॥
[illegible] ॥ [illegible] । [illegible]
[illegible] ॥

[illegible]

ॐ श्रीगणेशाय नमः

© Dharmarth Trust. Digitized By eGangotri

ॐ श्रीश्रीसिद्धलक्ष्म्यै नमः ॥ ॐ अस्य
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible] ३ ॥
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

© Dharmarth Trust. Digitized By eGangotri

अतं स्तूरण्य सहेवानयभू न
तानुरूं क्षि अथपानवनभा १
सेनकेकैर्वम नासन्ति क्षिमं वि
णिवरूपभुत्रः स्तु पञ्च काभित्रुता
विविष्णुर्के अचभिमं विष्णुं तवती
ति ३ तस्मै अदेवाय द्विविष्णुवे मि
त्रहङ्ति न स्मयसूक्र विमिवस्ति
यानि वतु पुरसमैव ४ तद्दुपा
दूमियन्नचयः सभवेसिञ्चवे
सः मित्र कल्येहू कां निफङ्के
कञ्चे होति यभिति मघपानययत
स्क्रनभुणिनस्तु ५ यतुस सूह

© Dharmarth Trust. Digitized By eGangotri

ससहसेनेत मद्वत्सम् सदाः स्तेहऽ पं
नि पं निहु विकुं मवणं त थ स्क्तं त
सहरं य क्तु ति येनिं पानि पद्मा ति पीनः
यपितुन्तोठः मप्रेतुण स्तुत म यथ
फपिह मुपण्यः मस्तवति । यथ म
तः पकपात्ता केमनेमणनितषुकरत्ता ।
मस्तवत्तीजवसुमा १ तपमानीयत
थस्तु तेत्रमु ठिरूयत पत्रास्तु नेम
नमंत्लेकः कमनमनमतमा ३
यः मचस्तुः मववितुस्तु स्तुनमयत
पः तमनेमतस्तु स्तुनमतु पमत्रास्तु
यत ॥ इति श्रीसुखमम ऽ कं सुखमः समाप्तः ॥

[illegible]

© Dharmarth Trust. Digitized By eGangotri

२

घकत्तुठय भेख्रूक्राविष्ठ्हृकैभान्हि
भचविष्ठ्हृस्लीभकि भजकुडन्हि ड्घ
भलभस्ठ्हुकै चमभकरनिवाल्हि
यत्हैंभचविष्ठ्हृक भणग्कुडन्हि भेख्रूक्र
यैविष्ठ्हृ भघव धवःभपानिमिघृ भक्
नभणेयंॐ कघनकत्तुठय धवःभक्
नभ णधि भध्रिभ मिघृ भक्लेन भणधि
ॐ भत्ठव न्हनन भवान्लहिठागहू
णधिॐ कघनकत्तुठय धवःठागहू
भध्रिमिघृ भक्लिनभ णधिॐ भ्रूक्र
वि॰ विष्ठ्हृक कघनकत्तुठय धवःभक्ली
३ नणधिक्लीभाल ॐ भेनकणधिघृग्ड

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

यदक्षभुक्त कर्तृक्रत्वनियिहृदि
यद्ववृक्षमक्तिउ उद्धंस्मृत्रवियययदस
वृक्षक्रदि यसमवृक्षक्रक क्ष्मनयाद्
क्रभूष्यिमि श्रुदिर्यद्वि समवृक्र्ती
क्ष्मनियिहृदि यरवृक्ष्किल्मनविन
मेवकोवन्दी यनुंभेवकें यन्नुथ
वृक्षक्रुद्दि त्यिमि क्षभुक्तकेंयकय
कीविक्रदि एकोयदयदविकु यट
मक्ष्मक्तिउ श्रुत्रवियनुपदि मिमीय
नविक्रदि त्यिमभुक्ववउ क्षभुक्त
कीविक्रुज कषनकादि उनंबुरुं
विक्रके यनुपञ्जंविभुर्भे कजनवद्

© Dharmarth Trust. Digitized By eGangotri

पुपमपुपरुविक्रुजं करदै। दैमीन
कठ्रेम: यस्वेम: गभवेम: मघच
वेम: पृरुम्रावमउषमिक्रुकल्न:
प्रुकलन: निरुजं कोलिउिय यरु
घट मरुदै मठधटनीकि परुज
किज्ञिउ पुउियमन कुवदै॥ मिक्रुकु
कुकु पालिनिटधदै वेम्रुकमेकि
कठउमू उरिभुनक लुनउषु म
रुकेधगकलुन मिक्रुमिदेवदै ॥०॥
कट्टय नटधिउष मम्रुलायनटधिय
नि कलनभमेरकोदै उिभविधि
वेम्रुठुकमुके मरुमुनकोगीउी

कि ५

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

मियक पल्ली वर्मे के उपयेणी देवि
मवमे के मक्क कदे हुवदे यिमना मि
लके मथलाविह कक वदे यम्पी
हुवमरिक कतुपद यत्रे वक्र वि
हुतुप उय निपडा कें मथलाविहु मठि
त्रपरा विहुतु पउ वहु वदी उम्पी
कद्ध उयभवाक वे मिभव कलुके य
तु उकम्रप्य उय भवाक घुउिपमक
वमकी ं कमथलाविहुतु पम विवक
उदे ॥ वैरा हुजमिभपवर भुक्षि मर्म
करीपुक धवेमुवल्ल करी एववक्र घुउि
पल्लउपयनि पडा दे मेउपावि पडांमप

ति

रविहु मनुगाउनकी किउधगवि
हुदै उघण्ठ विहुकाकेउहुनमार
वमुकुनिस्त्रै फेवउविहुकानमप
गविहुदै उश्चकावह्रकदेनिहुप
चकोदै कैभादैमक्कावमसेह्रियेक
मविधयदै उघणंमनुपणिरभिाकिउदै
उघवह्रयउकाह्रियहुमिण्उभिाकि
उदै उघूमण्ठीयविरण्ठीयभगउहै
भगकिउदै उघणिहुदै उघाहुपकदै
त्रकमारिकपह्रकुडुंकाकालदै
भेमक्कावकीभगउवकीवभकपेंकेगवि
ह्रयदै यगेंभक्कदै भेंमनार महुय

© Dharmarth Trust. Digitized By eGangotri

नभनस्मा ज्जिउहै रघमाकेंबिबीकें
धुमउपविश्वपड़ुपमोपिइँयकोहै
उमस्कसकीविठुनभवक्रस्टनव झुक्र
कीधुउिधुपमदकुउपविधउाउकदी
नभधागविठुहै मवउमभागस्टनमेम
वधुपड़ुकेंठवकमिठुवाभिउम्मुम
गड़ुइकेंभवधूपड़ुकाल्उम्मु ते
मधुउिधपनकोहै ॥ हैमेनकलैम
उत्तगठि ल्डुउपदीउहुवेगकउपाम
नकाल्रैं उघछयपकीनिभिउकालहै
यदीकें गठिउनिभिउुउपमनका
वधुकेंलेउहै ॥ उघमठिउनिभिउ ७

पृ० ७

पन्ननकान्नमामाकी भिद्रुतुमेष
क्षीकनभववेमि भि निलैयके यल्ल
मान्के ॥ मउंद्र कें संटूष ऽवेविवऊ:
पमिभुननकी ॥ लेमनवुतुपमेऽमन
लमेपकवी धापिवी मवीलऊमेन
नभूकनकनुक्रियवपमि ऊधपींषं
उद्धत्र केविकेऊमी पकपी सुद्धमिषापी
कःपीतुपमंमन कम्र द्रुमनउद्धवक
वकें केय सुद्धमेविममऊ उषपविद्मय
ऊमिषनकी पमिकंम्रमविनपनमद्ध
मापीकःपीतुपमंगनउद्धत्र रूवऊवें
यंम्रमेविममऊपविद्मयऊ यकुनं.कऊ
देष १

मणिभूननु
॥ पमि
मिष्टुनुष
भिपकेऊऊन

© Dharmarth Trust. Digitized By eGangotri

मिथाभक्कु कमन्नभनुमेनमि मिरोउप्ये
मामेकालेहि कलीयेलेविकेकम
ज्ञानभक्तुपथुपछुजमहेः मकामि
वतिमेउतुके उघन्नभक्तुपलेहि उघन्
सुहि पभ्भविरिमीमेछद्धत्रिकेमत्रवि
णयः मक्कुकेनिवेउवशि प्यमऊ
तुकेमूउिणावडीभूडिप्यनकाहि
लेमेलीवनमवभूविधेमेउनतुपकाके
भूमिकुलेयः पकपकेज्मेउनभूकमिक्
ण नायाकेमाल्लिभान्मिकुउद्धत्र त्रवि
हे उमेयज्ञेउनतुपमबामेलतुणणउ
उद्धत्रकवहि मछलाणउउद्धडीभूक्त

ति ३

© Dharmarth Trust. Digitized By eGangotri

कैंकदेदे स्णाउकीछूडी थुम्मथम
मुझ्स्णाउकैंविधयकाली वल्लेकु
नकाि भुल्लकैंउंकैं भूभुठय स्ले
मिधाविवीमें गिउवीसालल्लकैंम
भवुकाकें भुल्लउंकैंभू पउदेवेदे
थक्रमें भुल्लउंके स्णाउ्वकीछूडी
मझुल्लउ मझुधप्पनवी गम्भुल्लउ
कैंभूभुठये मकामेवुधवक्र मिम
गुरुउ लिम ह्ल नकलपनावल्ल ध्ध
उि किउठय: यहुपि महुहुउ मह्ल
नभिहुउमें मनामिदे यन्तुउंकेंउ
यउिकनीविशेठदे उथणपि स्णाउ।

© Dharmarth Trust. Digitized By eGangotri

उद्धृती कृत्वा मेखलान्तं उद्धृत्य कल्कं
भस्मना वृक्षकी भूमिं तु पञ्चकं
मर्हतं भूमिं देवदेवं पूजयित्वा ततः स्मरेत् प्रतिष्ठा च
हृदन्तं मस्तकं शिखां कवचं नेत्रम् अस्त्रं च
भिर्न्नंकि मन्त्रं पुष्पं मित्रं दक्षिणं उद्धृत्य ददेत् ततः,
तर्दितं दक्षिणं मे विरं उद्धृत्य देवतां
तं विरं उद्धृत्य ततः मन्त्रं कुर्यात् मित्रं
तेन उद्धृत्य देवतां ततः मन्त्रं मुख
मुखं मूलं देवं नाभ्यां लिङ्ग मध्ये क्रमतः
भेदन मित्रं पादतलं उद्धृत्य देवतां ॥
पृ.
७
देवेभ्यः कर्म भवनं पातालं कुक कर्म
रमा त्रुभ मभान्त्र त्रिलोचनं वाक्यं देवि

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

[illegible]

निर्विकल्प

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

۱۹۷۶

۲۶۴ ۱۹۱۹

۸ نومبر

۸۸

فیصدی سالانہ

۸ نومبر ۱۹۱۹

۶۳۱

۸ نومبر ۱۹۲۰

۱۶۵ / ۱۲۱

۱۲۲۹

© Dharmarth Trust. Digitized By eGangotri

SK 0464

Copy of F.D. Recpt No. SK 0464

No SK 0464.

Received from Mussttr. Radha widow guardian of & on behalf of [illegible] Ranai [illegible] & [illegible] Kunth Rania Major minors Rupees Eight hundred & eighty-five as a Deposit at the rate of five (5) per cent per annum repayable on the 8th Nov. 1920 on production of this Receipt.

Rs 885/-

Sd. [illegible]
for Acctt.

Sd. [illegible]
Manager
Cox & Co.

© Dharmarth Trust. Digitized By eGangotri

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

श्रीं तमनिल्लीं नयस्तत्वेत। सर्वंयमुमस्
वंसयेणयुक्तं तस्य सिमत्त। कुतुमुसनाम
नःसर्वेःमपुष्कल्लवाम। शुभ्रं तेषोगमूर्म
लमवमक्ष्विवालितः उ॑त्विल्लीनयस्मि
मेविमनलःकेवलःमुकः उ॑नेवमक्षतवन
धगमनस्य मस्तु धगमनस्य मस्तुऽस्ति॥ ॥
अथ चर्चवेसनत्सविस्तुपनिधक्षुम भ॥ ॥

तिमनेनिश्चिविपधेकं सत्कुमानसुमेवस
मसत्कुकमसक्कल्प सत्कुकमविवालितम।
मनानककमनमुत्तेक्कालंवनुमेक्ष्येः वनु
यविषयमक्षमक्षेनिचिषयंमत्तम। मेत
निचिषयमुत्तमनसेमुक्तिगिमुत। उक्तत्रि
चिषयंनितंमनःकालंमसुक्तते। निसुविष
यस्यक्षेशत्रिगतुमनेहालि। यस्ययहस
यीतवंसस्तुत्तमेयसम। उवसवनिसेतवं

© Dharmarth Trust. Digitized By eGangotri

यवकुटिं गंडमायभा [illegible]
[illegible] विभ्रः नैव [illegible]
[illegible]
[illegible]
[illegible]
[illegible] विचिकल्प [illegible]
[illegible]
विचिकल्प [illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

पि. ३

© Dharmarth Trust. Digitized By eGangotri

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible] ॥

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible] ॥
[illegible] ॥ ॥

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

लक्ष्मीनारायण
हृदयं स्तोत्र

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

येनः ॥ मघमिश्रवुनं ॥ भगवन्नाय
नमः ॐ ऐं क्लीं ठलं मनुष्याय स्वाहा
ॐ ऐं ह्रीं श्रीं नमाय श्रीयमस्वमरुण
ऋणाय अम्बरिमाय ऽ भूणन्तवगुरु
गुरुभगवन्नाय नमः ॐ ऐं क्लीं ठलं म
नुष्याय स्वाहा ॐ ऐं ह्रीं श्रीं विशक्रन्याय वि
रक्तन्याय मात्रिमिमाय पूवकणन्त
गुरु ३ भगवन्नाय नमः । ॐ ऐं क्लीं ठलं
मनुष्याय स्वाहा ॐ ऐं ह्रीं श्रीं रुमिंदाय
भिंदलन्याय मक्लिन्तिमाय यभणन्त
वगु १ भगवन्नाय नमः स्वाहा ॥ ॐ ऐं क्लीं ठं
ॐ ऐं ह्रीं श्रीं हिविरुभाय
ल मनुष्याय स्वाहा ।

© Dharmarth Trust. Digitized By eGangotri

ह्स्लें [illegible] माय [illegible]
[illegible] भट्टारकाय स्वाहा । ऐं ह्रीं
[illegible] मन्त्राय स्वाहा । ऐं ह्रीं श्रीं [illegible]
[illegible] पादुकां पूजयामि नमः
[illegible] भट्टारकाय नमः । ऐं
[illegible] मन्त्राय स्वाहा । ऐं ह्रीं श्रीं
[illegible]
[illegible] भट्टारकाय नमः ।
ऐं [illegible] मन्त्राय स्वाहा । ऐं ह्रीं
श्रीं [illegible]
[illegible] भट्टारकाय नमः ।
ऐं [illegible] मन्त्राय स्वाहा । ऐं ह्रीं

[illegible]
[illegible] नाय नमः।
[illegible]
[illegible]
[illegible]
य नमः। [illegible]
[illegible]
[illegible]
[illegible] नाय नमः। ॐ [illegible]
[illegible] ॥ सिद्धि
[illegible] ॥
[illegible]
[illegible]

© Dharmarth Trust. Digitized By eGangotri

ब्रह्मऋषिः अनुष्टुप्छन्दः ॐ ऐं बीजं
ह्रीं शक्तिः श्रीं कीलकं श्रीकमलाङ्कि-
ताय श्रीमद्भगवत्याः प्रीत्यर्थे मम
ऽभिष्टसिद्ध्यर्थे जपे विनियोगः ॐ ऐं नमो
भगवत्यै अङ्गुष्ठाभ्यां नमः ॐ ह्रीं निरञ्ज-
नायै तर्ज्जनीभ्यां नमः ॐ श्रीं चण्डिकायै म-
ध्यमाभ्यां नमः ॐ ह्रीं मङ्गलविभूतिभैरव्यै अनामि
काभ्यां नमः ॐ क्लीं त्रिभुवनेश्वर्यै कनिष्ठिका-
भ्यां नमः ॐ ह्रीं श्रीं [illegible] करतलकरपृ-
ष्ठाभ्यां नमः ॐ ऐं नमो भगवत्यै हृदयाय
नमः ॐ ह्रीं निरञ्जनायै शिरसे स्वाहा
ॐ श्रीं चण्डिकायै

© Dharmarth Trust. Digitized By eGangotri

मायायवधहे ह्रीं श्रीं भगवति भूवे
कव मायायं ह्रीं क्लीं विश्वरूपाय श्रुयत
हं हं यायविधहे ह्रीं श्रीं सौं राय मर्म
य ठ ल ऽ ठि धर्मस्वाहा भः । मध कव
से ॥ सिद्धिनाम्याशं सा त्रैं ई वकोति
रथ्न भो भावि न सिं न व के उ ऊष्णं वि
भूभ तत्वं पश्यु वागां ह र के उ कु
ङ भु पशु न मु रभो ऊं ह्रुं भा उ वि र के
अ ह्म्य म भु अ स्तं व ह्रुं प म्ना
ठि स्त्र क ध्रिं र के ति वि र ह ऽं ल उ प्य:
सीणं र के अ उ लु ये र उ नी प:
पले श्ग सी म्लं र के म वे म प न म ष्ट्रभो

© Dharmarth Trust. Digitized By eGangotri

इति कवचमाला ॥ ॐ ऐं ह्रीं श्रीं क्लीं
ह्रीं श्रीमालिनीनाथाय ज्योतिर्लिङ्गाय त्रिं
ग्य भक्तविभूतिविधायकाय नमो न
मः ॐ ऐं ऐं ऐं ऐं ऐं नमो मायामोह
यमाय मन्त्रप्रेतभग्नपीठभुवनायमा
मेघनादाय नमो नमः । ॐ में में में में में
ॐ नमो निष्कलङ्काय निष्कलङ्काय त्रिवि
कल्पाय निर्विकल्पाय नमो नमः ॐ
क्लीं ह्रीं श्रीं ह्रीं ॐ नमो शिवविश्वमायाहि
पालयहिलि हुलन्धाय हुं श्रिकाय
हिरण्याय नमो नमः ॐ ऐं ॐ ऐं श्रीं ऐं
नमो श्रीनाथाय

© Dharmarth Trust. Digitized By eGangotri

श्री निवाभाय भग भों क्रूय भानाय
यनमोनमः ओं श्रीं ह्रीं गीं हूं लीं धुं ह्रीं
ओं नमो भगवते विश्वेश विश्वरूपाय विश्व
गर्भाय विश्वहृदयकाय विश्वधराय
नमोनमः ओं ह्रीं ह्रीं क्लीं क्लीं क्लीं क्लीं
क्लीं क्लीं कं ओं नमश्च मित्राय मित्राय
यमदाय कूर्माय कृष्णरूपाय वज्रपाणये
नाय हिरण्यकरुणाय नमोनमः ओं
ह्रीं श्रीं सिद्धिरूपाय मम नैरुजता १ धा क
ओं ह्रीं श्रीं तमित्राय मम आयुरस्तु ३
धा क ओं ह्रीं श्रीं हिरण्यभाय मम
ओं ह्रीं श्रीं श्रीणाय
कल्याणं १ धा क

यमत्रुत्रुहं रक्ष २ ॐ ऐं ह्रीं श्रीं वि
षुदाय मम कण्ठं रक्ष २ ॐ ऐं
ह्रीं श्रीं यज्ञनाभाय मम नाभिं रक्ष २ ॐ
ऐं ह्रीं श्रीं वामनाय मम कटिं रक्ष २
ॐ ऐं ह्रीं श्रीं श्रीधराय मम गुह्य
ध्रं रक्ष २ ॐ ऐं ह्रीं श्रीं श्रीप्र
येक्षभाय मम ऊरुद्वयं रक्ष २ ॐ ।
ऐं ह्रीं श्रीं दामोदराय मम पादौ रक्ष २
ॐ ऐं ह्रीं श्रीं पाभेश्वराय मम
चरं रक्ष २ ॐ ऐं ह्रीं श्रीं नाराय(ण)
य मम भवसङ्कटं २ ॐ ऐं ह्रीं
श्रीं त्रिविक्रमाय मम भवसमुद्र नौकील

© Dharmarth Trust. Digitized By eGangotri

य १ स्वाहा ॐ ऐं ह्रीं श्रीं भभभव मह
चानिक्रुतय निकृन्तय स्वाहा ॐ ऐं ह्रीं
श्रीं भक्त विघ्नान् भूभभव महत्ना विघ्नं
भय १ स्वाहा ॐ ऐं ह्रीं श्रीं श्रीं णन्य भ
भभवमहत्ना क्रोमय १ स्वाहा ॐ ऐं ह्रीं
श्रीं वाराणय भभभव महत्ना नमय
भवन्ना नमय स्वाहा ॐ ऐं ह्रीं श्रीं क्लीं
श्रीं पीं पीं भवे सुरूपू भूभभव महत्ना
ठमाय १ स्वाहा ॐ ठिं ठिं ठिं मं मं मं धं धं
धं रं रं रं मां मां मं मं मं मं ठं ठं ठं लं लं
लं इं इं इं ऊं ऊं ऊं मं मं मं ठं ठं ठं वं वं वं
ठं ठं ठं ऽं ऽं ऽं मि गैं गैं गैं गैं गैं अमा गैं गैं

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

© Dharmarth Trust. Digitized By eGangotri

नमः ३ स्वाहा ह्रीं श्रीं ब्लूं स्त्रूं पाययम
वरेणाय नमः ३ स्वाहा ह्रीं क्लौं सौं सौं
सायंभवरेणाय नमः ३ स्वाहा ह्रीं
क्लीं ह्रिं विद्युभाय भवरेणाय नम ३ स्वाहा
भवाकं वउ रुद्राय पाय सीरुद्राय व
ज्रुरुद्राय नन्दीरुद्राय अरुरुद्रायपद्
रुद्राय वायुरुद्राय भयरुद्राय वरु
रुद्राय नमरुद्राय पीनरुद्राय पी
र्युरुद्राय पीनीरुद्राय नाकी
रुद्राय मानकीनरुद्राय क्रुरुद्राय
धुरुद्राय वीरुद्राय वेतालरुद्राय
भद्ररुद्राय यन्त्ररुद्राय लललरुद्राय

© Dharmarth Trust. Digitized By eGangotri

त्वरव भवत्यपराजितायै स्वाहा पवतिश
रूनभवरूनविपरूनपवरूनपनत्र
मूभरून ऐंह्रींश्रीं चामुण्डायै भव
रूनचोवकु १ भरून ऐंह्रींश्रीं चाम
ण्डायै भवरूनयचिकृत्वाय भव
रूनयलींत्रीं भरून ऐंह्रींश्रीं न
सिंनय भवरूनयनिवृजय पित
जय भरून ऐंह्रींश्रीं न लीपन्नय भ
वरूनचोकेनय १ भरून ऐंह्रींश्रीं
नं भनाविसूव भवरूनयविभ्रमाय १
भरून ऐंह्रींश्रीं नं विभ्रमाय ञ्जय
भवरूनयामय १ भरून ॥

पं ३

© Dharmarth Trust. Digitized By eGangotri

नमय स्वाहा ह्रीं श्रीं हं हिवि क्रूम
यभवभ्यो नमः इमय १ स्वाहा ह्रीं
श्रीं ह्रीं नं श्रिं श्रं क्लीं क्लीं श्रीं भवस्या
यभूयभ्यो नमः नमूउ १ भग भमय १ मं
ग ह्रीं हं हं हं धं हंनमेहिवि क्रूभाय
पद्मनाभाय श्रीधराय गयशीवाय
भवपद्मनाभाय १ उरुक्रमाय १ श्रं
ग उधयय उपयय सिधयय १ विनामय १
नमय १ स्वाहा इमय १ धीडय १
शुमय १ स्वाहा ह्रीं श्रीं धराय हिविह्र
भाय श्रनन्तभूत यं पद्मनाभाय भग
धेउभाय श्रीं हं हं ॐ हं ठठ स्वाहा

© Dharmarth Trust. Digitized By eGangotri

ॐ हयशीवाय च ब्रह्मण्याय च नरोत्तमाय उ
त्तिष्ठरूपाय पूर्णाधिपत्याय ॐ कं कं डं ल
श्रङ्क वीरं भीयर्त्रे लक्ष्मीपतये ॐ ह्रीं
श्री नारायणाय भूमिमहत्तमजनार्दनाय
नमो नमः ॐ नमो विराट्स्वरूपाय विनायक
नायनमो नमः ॐ नमो भैरवसिंहाय सिंह
नायनमो नमः ॐ नमो भूतभावनाय
पालिनायनमो नमः ॐ नमो भूतपालनाय भूत
य यज्ञपुरुषाय नमो नमः ॐ नमो भूत
यशीवाय हृषीकेशाय नमो ॐ नमो श्री
मद्वसुरूपाय रामलक्ष्मणाय नमो नमः
ॐ नमो श्रीकृष्णरूपाय कामरूपाय नमो नमः

ॐ ७
वि ३

© Dharmarth Trust. Digitized By eGangotri

नमो ...पाय महोमाय भक्तिप्रदाय नमो
नमः ॐ नमो भगवते पीतवर्णाय परमेश्वराय
नमो नमः ॐ नमो भगवते ... ाय ...
...पाय नमो नमः ॐ नमो भगवते ...
य ... नमो नमः ॐ नमो भगवते
... विष्णवे विश्वरूपाय नमो नमः ॐ
नमो भगवते ... य ... वाय
नमो नमः ॐ नमो भगवते ... वाय वाम
य नमो नमः ॐ नमो भगवते ... पाय
... य नमो नमः ॐ नमो भगवते ...
पाय ... य नमो नमः ॐ नमो भगवते
वा... ... वाय वि... ... य नमो नमः

© Dharmarth Trust. Digitized By eGangotri

नमः श्रीभगवते भवभयहरणाय नमो
नमः ॐ नमः श्रीपरमशिवनाथाय
नमो नमः ॐ नमः श्रीभैरवरूपाय भग
वन्नाथाय नमो नमः ॐ नमः भवभेदाय
त्रिगुणाय नमो नमः ॐ नमः त्रयम्बकाय
य घघचण्डाय नमो नमः ॐ नम
स्त्र्यम्बकाय महाभाय नमो नमः ॐ नम
श्शिवकान्तवल्लभाय नमो नमः न
मस्तुलसीकान्ताय कमलाकान्ताय
नमो नमः ॐ नमस्त्रिकालनाथाय भग
वत्कालाय नमो नमः ॐ नमस्त्रिकभैरव
य कमलाय नमो नमः ॐ नमस्त्रि

© Dharmarth Trust. Digitized By eGangotri

ग्रस्त्व भग्वुनकन्ययनमेनमः ॥
डतिश्रीवन कभरालिभभैवमविणं
फश्रीणल भैवानू श्रीभकनरयन
भहरलभुंहमित्र भालिभमुलं ॥

पिभैनययश्रुय ॥ भघनययन
हमयंलिभुउ ॥ पिभश्रुमीनयय
नहमयभुडभहूष भकुघल णषिः
मनभुकः हिमु पाणयद्दी यघ
यंकः भहुम्र डतिकीलकं श्री
हभुःपाभभुमवउ श्रीविघ्नश्रीह
हेपं विनियोगः ॥ भकुघल उवाच ॥

© Dharmarth Trust. Digitized By eGangotri

स्तिमम रतमरु विष्णुः प भूतक्ष पिके
सवः गोविन्दसाखिलं पाक्षेव भेत भग
भगवः उपारिष्णु क्षवतोल्प वगकःप
भिवीतल भवंत्रा क्लिमियः सुपुप
भवभभागवः गछ्छतभिसुतवापि
सपुतःसुभतपिव वगभिकततत
श्रीवाभवभयेहुरं सहतंसेव
सुर्योनिंवपाति हतंमेकसीतभय
नतिम वाकिंवतंभर भक्षिसनेर
क्लिसःसुरेपूल भाकक्षवायभा
वामंवस हुसयंमूनिरक्ष पसीप
मितुप कणेभक्तुपः भक्लिपाकृहपि
मिवतक्ष

© Dharmarth Trust. Digitized By eGangotri

विहरूपभ्रमग्र षभभडुं ऊँ अवर
वंमालंभूपहे यह्ह्रक्कं भवति
कथदिशु परैवोःहं वरंऊं वरिशु
श्रृक्लभीमंमालंभूपहे स्रहे ध
नपभीमांनभनत्तुंधनसुत्रभा ऊ
भैरकारंबुकू हूक्षो हूकॆं भनाउं नं
भकठारुभनाहूनं ज्ञानकेुं हूं भक्ष्य
ऊमा केसवूणांमणक्षम कीउयत्र
वभीमति पिडुःभनधाय भनपदु
धाय वाभऊवाय नभेनमः पिडु
वाभनधाय भनपदुधाय वाभऊवं
यवभेनमः पिडुःभनधाय भनध
© Dharmarth Trust. Digitized By eGangotri

त्रुपाय वामदेवाय नमो नमः ॐ क्रु
द्धाय क्षेत्रपालाय क्षेत्रपालाय वामदे
वाय नमो नमः ॐ अजराय क्षेत्र
पालाय ॐ इन्द्रमूर्तये क्षेत्रपालाय ॐ कू
ष्माण्डाय क्षेत्रपालाय वरुणाय क्षेत्र
पालाय ॐ बटुकाय क्षेत्रपालाय ॐ वि
मुक्ताय क्षेत्रपालाय ॐ लुप्ताय क्षे
त्रपालाय ॐ ऐरावताय क्षेत्रपालाय ॐ ओ
षधिघ्नाय क्षेत्रपालाय ॐ लीलकाय
क्षेत्रपालाय ॐ दिव्यकाय क्षेत्रपालाय ॐ भी
षणाय क्षेत्रपालाय ॥ ॥
ॐ एकदंष्ट्राय क्षेत्रपालाय ॥ ॥
© Dharmarth Trust. Digitized By eGangotri

ॐ [illegible] [illegible]य भूतनाथाय ॐ [illegible]
[illegible]ाय भूतनाथाय ॐ [illegible]ाय भूतनाथाय
ॐ क्षीणाय भूतनाथाय ॐ [illegible]
य भूतनाथाय ॐ [illegible]ाय भूतनाथाय
ॐ [illegible]णाय भूतनाथाय ॐ [illegible]ाय
भूतनाथाय ॐ [illegible]ाय भूतनाथाय ॐ
[illegible]ाय भूतनाथाय ॐ [illegible]ाय भूत
नाथाय ॐ [illegible] भूतनाथाय ॐ [illegible] भूतनाथाय
ॐ [illegible]
य भूतनाथाय भूतनाथ[illegible]ाय लक्ष्मी[illegible]
[illegible] नमः ॐ
[illegible]
[illegible] लक्ष्मी[illegible]

© Dharmarth Trust. Digitized By eGangotri

जननाम्नोऽस्तु ते भगवति भुवनेश्वर्यस्तु
ते भगवति सर्वमान्याऽस्तु ते भगवति स
र्वमंगलायाऽस्तु ते भगवति सर्वशक्त्या
ऽस्तु ते भगवति सर्वशक्तिमयाऽस्तु ते
भगवति सर्वीयमानाऽस्तु ते भगवति सर्व
क्रमणी भव क्रमणी भगवति सर्वेक
रूपसमस्तभवमूलस्थे भगवति नमो
नमः सर्वभूतसर्वलोकमयि भग
वति सर्वदेवमयि सर्वरूपिणी भगवति
सर्वभूतशक्तिस्वरूपे भगवति सर्व
मयि सर्वमन्त्रमयि भगवति सर्वलोक
सृष्टिस्थितिसंहारकारिणी भगवति सर्वेश्वरि

६९३

फलश्रुतिं यः पठेद् विशेषल्लक्ष्मीं स
न्ध्यायां [illegible] प्रभाते [illegible] इति स
[illegible] यः पठेत् । ॐ ह्रीं [illegible]
भगवत्यै लक्ष्मीनारायणाभ्यां [illegible]
विष्णवे नमः ॥ ॥
इति श्रीलक्ष्मीनारायणहृदयं स
माप्तम् ॥ शुभमस्तु सर्वदा ॥ ॥
ॐ तत्सत् ॥ ॥ ॥

© Dharmarth Trust. Digitized By eGangotri

~~अनीत पत्राभि~~ गीता सार

[illegible]

© Dharmarth Trust. Digitized By eGangotri

रिस्त्रीलच्छायया साम्येनमः रिपुज्ञानतत्त्वान ॥ यस्तत्त्विकलं
वृक्षेहे मा सीतं निरञ्जनम् । कैवल्यं केवलं सान्तं सुसूक्ष्मं तत्त्व नि
र्मलम् । ० सम्भूतक्रमविच्छेद्य विन्मेस्फुरितवल्लितम् । ह
न्येयोगाविनिमुक्तं तच्चतं ध्यानि कोऽस्य व ३ श्रीगतसंपत्त्वान
सवेतोऽत्थितकान्तं सत्त्वशुद्धमुण्ज्ञितम् । सत्त्वः प्रास
स्वनसत्यं प्रासं प्रासम् । ३ सन्निधिनिर्णयं सर्वं सत्ते

© Dharmarth Trust. Digitized By eGangotri

𑆠𑆴𑆫𑆴𑆠𑆴𑆱𑇀𑆡𑆮𑆩𑇅 𑆖𑆢𑇀𑆢𑆶𑆠𑇀𑆥𑆫𑆩𑆘𑇀𑆚𑆁𑆱𑆩𑆱𑇀𑆡𑆴𑆠𑆶𑆬𑆮𑆬𑆴𑆠
𑆩𑇅 𑇓 𑆮𑆴𑆱𑇀𑆛𑆪𑆠𑇀𑆫𑆼𑆤𑆑𑆼𑆠𑇀𑆠𑆪𑆢𑇀𑆢𑆩𑆳𑆨𑆬𑆩𑆲𑆪𑆩𑇅 𑆪𑆼𑆩𑆼
𑆥𑆫𑆩𑆠𑇀𑆠𑇀𑆮𑆼𑆤𑆱𑇀𑆮𑆳𑆤𑇀𑆢𑆮𑆠𑆁𑆱𑇀𑆮𑆩𑇅 𑇔 𑆱𑆶𑆱𑇀𑆛𑆶𑆤𑆳𑆩𑆪
𑆥𑆴𑆤𑆼𑆱𑇀𑆛𑆼𑆁𑆪𑆨𑆶𑆑𑇀𑆠𑇀𑆪𑆶𑆱𑇀𑆡𑆠𑇅 𑆱𑆶𑆩𑆼𑆫𑆩𑆪𑆪𑆩𑆁𑆱𑇀𑆮𑆠𑆴𑆂
𑆑𑆶𑆨𑆮𑆩 𑇕 𑆱𑆑𑆬𑆁𑆠𑆶𑆩𑆤𑆱𑇀𑆑𑆳𑆫𑆁𑆤𑆴𑆱𑇀𑆑𑆬𑆁𑆣𑆳𑆩𑆁𑆥𑆫𑆩𑇅
𑆱𑇀𑆥𑆶𑆫𑆤𑇀𑆠𑆴𑆩𑆳𑆤𑆶𑆮𑆼𑆠𑆼𑆩𑆮𑆱𑇀𑆠𑆶𑆢𑆼𑆮𑆴𑆮𑆠𑆂 𑇖 𑆱𑆶𑆩𑆴𑆨𑆘𑇀𑆚

© Dharmarth Trust. Digitized By eGangotri

भजरवेदद्युसमस्तुनाद्भय भूमा॰ वेदसुद्धरसस्तुसीत
ठियेगिनाम्। ३ ठेधांसविञ्छुउविधुस्तचैः पाधानुक्तिं
भस्त कषिउंसभयिद्धुनंसवनाभपिद्दलठम्। ७ वि
वकउपमयंमितुं ठैरवदुतुिविकृना षधुकममिमं
भस्त्रंयस्मयाकपिउंउव १० सनिहंपिहउंयाउंयसठ
श्रीः ९ वंसपस्तुउि नाहंनिगस्नाक्संनिवा॰ स्तुपमीस्तुरम्। ११

© Dharmarth Trust. Digitized By eGangotri

𑆱𑆤𑆒𑆁𑆤𑆴𑆠𑇀𑆫𑆶𑆬𑆁𑆩𑆤𑇀𑆑𑆳𑆑𑇀𑆫𑆖𑆫𑆩𑆩𑆮𑆑𑇀𑆫𑆴𑆠𑆩𑆳𑇅 𑆩𑆮𑆠𑆢𑇀𑆫𑆶𑆪𑆫𑆁𑆧𑆶
𑆑𑆮𑆱𑇀𑆑𑆶𑆩𑆳𑆥𑆴𑆤𑆮𑆑𑇀𑆲𑆶𑆠𑇀 𑇑𑇒 𑆩𑆲𑆴𑆠𑆜𑆮𑆱𑆪𑆼𑆢𑇀𑆫𑆤𑆑𑆵𑆫𑆁𑆽𑆬𑆼𑆑𑆳
𑆮𑆑𑇀𑆫𑆴𑆠𑆩𑆳𑇅 𑆱𑆩𑆩𑆁𑆱𑆳𑆢𑇀𑆫𑆶𑆬𑆁𑆲𑆥𑆶𑆤𑆳𑆜𑆼𑆜𑆑𑇀𑆫𑆴𑆑𑆥𑆳𑆑𑇀𑆫𑆴𑆠𑆩𑆳𑇅 𑇑𑇓
𑆬𑆵𑆮𑆼𑆪𑆪𑆶𑆩𑆬𑆵𑆪𑆼𑆠𑆩𑆑𑆬𑆳𑆒𑆼𑆠𑆣𑆵𑆩𑆳𑆠 𑆝𑆪𑆳𑆩𑆮𑆮𑆩𑆴𑆑𑆁
𑆲𑆥𑆶𑆁𑆫𑆽𑆬𑆼𑆑𑆁𑆩𑆱𑆫𑆳𑆱𑆫𑆩𑆳𑇅 𑇑𑇔 𑆮𑆑𑇀𑆫𑆼𑆲𑆮𑆑𑇀𑆫𑆴𑆮𑆴𑆥𑆶𑆠𑆁𑆮𑆼𑆑𑆠𑆶
𑆣𑆶𑆫𑆠𑆴𑆑𑇀𑆫𑆶𑆠𑆩𑆳𑇅 𑆝𑆁𑆮𑆑𑇀𑆫𑆮𑆼𑆑𑆩𑆴𑆲𑆑𑆮𑆼𑆑𑆤𑆁𑆥𑆫𑆩𑆁𑆥𑆑𑆩𑆳𑇅 𑇑𑇕

© Dharmarth Trust. Digitized By eGangotri

[illegible] 𑆮𑆴[illegible] 𑆪𑆼𑆤 𑆨𑆮𑆴[illegible] 𑆣𑆳𑆫𑆟𑆳𑆂 [illegible]

[illegible] ०१ 𑆓𑆳𑆪𑆠𑇀𑆫𑆵𑆁 𑆨𑆮𑆴[illegible]

𑆨𑆮𑆴[illegible] । ०२

[illegible]

[illegible] ०३ [illegible] 𑆓𑆵𑆠𑆳[illegible]

[illegible] 𑆮𑆢𑆤𑇀𑆩𑆳𑆠𑆫𑆁 । 𑆮𑆴𑆩𑆬𑆁 𑆮𑆴𑆩𑆬𑆳𑆑𑆳𑆫𑆁 [illegible] । ०४

© Dharmarth Trust. Digitized By eGangotri

शङ्खविष्णुः महाविष्णुर्वारिजप्रकटप्रकटः भक्तिविश्ववन्द्यैव
योगिध्येयाऽतिमधुरः ९० निष्प्रपञ्चो योगीशः शङ्खविष्णुः स्व
स्थः ॐ वैगतद्भवश्च पिङ्गलाद्यवनीयकः १० [illegible]
किल [illegible] तिः परिकीर्तितः [illegible] वहिः प्र
[illegible] लमेवम ११ [illegible] नित्यभाङ्गवत्सम
[illegible] ईशितम्भवः [illegible] संभवभा १२ प्रणीतं [illegible] कत्वं

© Dharmarth Trust. Digitized By eGangotri

[illegible]
[illegible]
[illegible] । [illegible]
[illegible] । [illegible] ।
[illegible] ॥ [illegible]
[illegible] । [illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible] ।११ केवलं केवलं [illegible] ।
[illegible] ।१३ श्रीभगवानुवाच ।
[illegible] ।
[illegible] १७ [illegible]
[illegible] २० [illegible]
[illegible] ।
[illegible] ।

© Dharmarth Trust. Digitized By eGangotri

३३

वस्त्रं नगमस्तुति उत्तीर्णस्तु परमपदे नावन्ति किं भयेऽलनमा | ५

रूपेणाप्तिरूपमुक्तः पिण्डमुक्तः पिण्डबलितः समभेले निर्मलः

शुद्धः भवदृष्टीनिरञ्जनः ३३ [illegible]

[illegible] | [illegible]

[illegible] ३४ ॐ [illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

ी
३

यं ध्रुवमूर्तः ३१ श्रीदः श्रीशः कर्ता कर्तुः किंभर्तुः मातृभक्तः
यः धर्मधर्म्मनाथश्च भाषपद्मविनतः ३२ श्रीतारा
कं पीयूषक्रुद्धेलक्ष्मनविशुद्ध भवसागरमयी श्रीत भवदक्ष
यीतक भवती क्रमयी श्रीत अक्षर श्रीत भभहमेत। ३३ श्री
कलावार्तवत्स विंकारशनिनाम्मववावभवगत्वतिकनि
रालक्ष्मंउत्क्रान्तं यत्शान्मिलयंगतः ३४ निरालम्बमम्ब

© Dharmarth Trust. Digitized By eGangotri

भुक्तिर्निर्मलतां शान्ति निवृत्ति क्रियया प्रचार्यं तं वेद स वेद
वित् ॥ २० ॥ [illegible] लीले लीलवति लीलावननाधिपे ली
लभलीलवितमा ॥ [illegible] लीलाके [illegible] लीलवति ॥ २० ॥
[illegible] भापनाभिकये [illegible]
[illegible] लीलाके [illegible] लीलवति ॥ २१ ॥ [illegible]
[illegible] भनाभिकमा ॥ [illegible]
[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

© Dharmarth Trust. Digitized By eGangotri

द देहं त्यजेत् । गङ्गा गीता च गायत्री गोविन्द हृदि संस्थिता ॥ ५१ ॥ चतु
[illegible] : यः [illegible]
[illegible] संस्मृतिः ॥ ५३ ॥ [illegible]
[illegible] ॥ ५४ ॥ गीतार्थं [illegible] विष्णुः लोके [illegible]
[illegible] ॥ [illegible]
३ [illegible] ॥ ५० ॥ [illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]

© Dharmarth Trust. Digitized By eGangotri

यः

ॐ नमो नारायणाय

त्रिभिर्नारायणाय

[illegible] मुनिकायमिसुमिः [illegible]

[illegible] मुनिः

त्रिभिर्नारायणाय

© Dharmarth Trust. Digitized By eGangotri

अज्ञात पत्राणि

यंभुवि य भ भनु भू[illegible] य भ भू[illegible] ॥ [illegible]

[illegible] भ भ [illegible] य भः ॥ [illegible]

भ[illegible] य [illegible] भ [illegible]

भ[illegible]ः [illegible] ॥ [illegible]

[illegible] भाप भ भवं ॥ [illegible] य भः ॥ [illegible]

भ[illegible]ः [illegible] ॥ [illegible]

भ[illegible] [illegible] ॥ [illegible]

भ[illegible]ः ॥ [illegible] ॥ [illegible]

[illegible]

[illegible] भ भ [illegible] ॥ [illegible]

[illegible] ॥

[illegible] भ [illegible]

© Dharmarth Trust. Digitized By eGangotri

ॐ स्वस्ति सिद्धं अआइई उऊऋॠ
ऌॡएऐ ओऔअंअः कखगघङ
चछजझञ टठडढण तथदधन
पफबभम यरलव शषसहक्षः ॥
ङाञाबाणा जगजज्ञ हहूस्रोक्षः
कोखकञ्चकञ्जल्कनञ्चकचत्रः
ककाकिकीकुकूकेकैकोकौकंकः
खा

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

[illegible] ۱۷ [illegible] ۱۹۷۹

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]
[illegible]
[illegible] ॥१॥ [illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible]
[illegible] ॥३॥ [illegible]
[illegible]

© Dharmarth Trust. Digitized By eGangotri

[illegible]

[illegible]

[illegible]

© Dharmarth Trust. Digitized By eGangotri

۳۰ سال کی ۱۹۴۵
سکھ ساکھ
[illegible]

اوم سری

۱۹۴۵

مبارک ساکھہ ۳

بتاریخ ۳۰-۷-۱۵

سکھ ساکھہ شروع ۱۹۴۵

مکان میں

[illegible]

© Dharmarth Trust. Digitized By eGangotri

ہری اوم

یادداشت

۱۵ اسوج بدی سمبت ۱۹۷۵ منگلوار کو شروع

ترتیہ چترم لوک — چندرہ وار —

مطابق ۸ مئی ۱۹۱۸ء

تاریخ مذکورہ پر راجہ بھوج کی عملداری کتاب میں

معزز و شروع ہوئی۔

ابتدا سے انجام تک بخیر

تو رام جی حافظ ہو۔

آد ... کرم ... تک کرنا

۱۹۷۵

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

पूर्ण

© Dharmarth Trust. Digitized By eGangotri

= ३४....

अतिक्ष्ण गा॥ [illegible] गा॥ [illegible]॥ [illegible]

०१५३...॥ [illegible]...॥ [illegible]...॥ २४४...॥

[illegible] वा यः [illegible] यिनि, = ३४...., [illegible]

[illegible] वि, [illegible] का लि ना, [illegible] के

[illegible] यु: [illegible] हि मि [illegible] का [illegible] वक

७. [illegible] का [illegible], [illegible] वा [illegible]

[illegible] वि [illegible] का ला [illegible]

वि [illegible] यु मि है [illegible] मि [illegible] मि

[illegible] विक्ष्णु कि [illegible] है [illegible] वा कि [illegible] का

[illegible] वि [illegible] का [illegible] कि

विक्ष्णु [illegible] वि [illegible]

[illegible] यु मि है [illegible] मि [illegible] का [illegible]

[illegible] कि [illegible] है, [illegible] ना, यिनि, ०० [illegible]

[illegible] ना [illegible] का [illegible] यिनि [illegible] मि [illegible]

[illegible] यु मि है [illegible] मि का [illegible]

मि [illegible] है [illegible] वा कि [illegible]

© Dharmarth Trust. Digitized By eGangotri

ਸਕੂਟੰਸ ਕ੍ਰਤ

੩ | ੩੧

ਤਸ ਅਸ ਅੰਤੁ ੩ ੮-

ਬਾਬਾ ਜੀ ਕਿਸਕ

ਸੋ ਖੁ ੳ ਤੂ:

ਪਿ੍ਸ੍ਰਿਤਿ ਆਏ

ਖਰਸੂ ਸੇਵਕੈ ਹੋਏ

[illegible] ਕ [illegible] ਸਤ

ਸੁ ਠਾ ਨ ਸੁਿਧਤ

[illegible] ਕੇ [illegible] ਕੀਤਿ ਸਤੈਪਿ

© Dharmarth Trust. Digitized By eGangotri

360.

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri

© Dharmarth Trust. Digitized By eGangotri